ॐ

धार्मिक—सज्जनोपयोगिनी

पंडितकेशवभट्टज्योतिर्विदा

संस्कृता—शोधिता

स्तोत्रावलीसंवलिता च

इयम्

ग॰रा॰ज्ञा॰ शारिकासहस्रनामावली
शिव॰ सूर्य सहस्रनामावली
भवानीनामसहस्र मुम्बय्यां नामावली

निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा प्राकाश्यं नीता।

सप्तर्षिसंवत्सरे ५००३, विक्रमसंवत्सरे १९८४,
ईस्वीवत्सरे १९२७.

परोपकाराय प्राकाश्यं नीता।

मूल्यं ॥-) ।

Printed by Ramchandra Yesu Shedge, Nirnaya-sagar Press,
26-28, Kolbhat Lane, Bombay.

Published by Keshavbhatta, Patha Shala Teacher, at Nonar,
Post Mahashahibhag, Srinagar, Kashmir.

अथ महाराज्ञीसहस्रनामस्तोत्रम् ॥

श्रीदेवी । भगवन्वेदतत्त्वज्ञ तन्त्रमन्त्रविचक्षण । शरण्य सर्वलोकेश शरणागतवत्सल ॥ कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् । मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ श्रीभैरवः । या देवी निष्कला राज्ञी भगवत्यऽमलेश्वरी । सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति । अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ परमार्थप्रदं पुण्यं परमैश्वर्यकारणम् । सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम् ॥ समस्तशोकशमनं महापातकनाशनम् । सर्वमन्त्रमयं दिव्यं राज्ञीनामसहस्रकम् ॥ अस्य श्रीभगवतीराज्ञीनामसहस्रस्य, ब्रह्मा ऋषिः, गायत्रं छन्दः, श्रीभूतेश्वरीराज्ञी देवता, ह्रीं बीजं, सौः शक्तिः, क्लीं कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं महाराज्ञीप्रसादसिद्ध्यर्थं पाठे होमे वा विनियोगः ॥ रां रीं रूं रैं रौं रः इति न्यासः प्राणायामः ॥ ध्यानं ॥ उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां सिंहासनोपरिगतामुरगोपवीताम् । खड्गाऽम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीं भजामि विकसद्वदनारविन्दाम् ॥ ॐराज्यप्रदायै विद्महे पंचदशाक्षर्यै धीमहि । तन्नो राज्ञी प्रचोदयात् ३ मूलं ॐह्रीं श्रींरांक्लींसौःभगवत्यैराज्ञ्यैह्रींस्वाहा १०८ ॥ श्रीभैरवः ॥ ॐह्रींश्रींरांमहाराज्ञी क्लींसौःपञ्चदशाक्षरी । ह्रींस्वाहा त्र्यक्षरीविद्या पराभगवती विभा ॥ भास्वती भद्रिका भीमा भर्गरूपा महस्विनी । माननीया मनीषा च मनोजा च मनोजवा ॥ मानदा मन्त्रविद्या च महाविद्या षडक्षरी । षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी । महालक्ष्मी

महोरस्का महौजस्का महोदया ॥ मातङ्गी मोदकाहारा मदिरारुणलोचना । साध्वी शीलवती शाला सुधाकलशधारिणी । खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता । हृत्पद्मवासिनी हृद्या पानपात्रधरा धरा ॥ धराधरेन्द्रतनया दक्षिणा दक्षजा दया । दयावती महामेधा मोदिनी बोधिनी गदा ॥ गदाधरार्चिता गोदा गङ्गा गोदावरी गया । महाप्रभावसंहिता महोरगविभूषणा ॥ महामुनिकृतातिथ्या माध्वी मानवती मघा । बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी । शारी शरीरमध्यस्था वैखरी खेचरीश्वरी । शिवदा शिववक्षःस्था कालिका त्रिपुरा पुरी ॥ पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी । बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ मुण्डमालाञ्चिता मुद्रा क्षोभदा कर्षणक्षमा । ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी । नारसिंही भैरवेशी भैरवाकारभीषणा ॥ नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी । नागकङ्कणकेयूरा नागहारा सुरेश्वरी ॥ सुरारिघातिनी पूता पूतना डाकिनी क्रिया । क्रियावती कुरी कृत्या शाकिनी लाकिनी लया ॥ लीलावती रसाकीर्णा नागकन्या मनोहरा । हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ स्रहासिनी मधुमती सरश्रीः सरमोहिनी । महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ सुधामयी वेणुकरा वैरहा वामसुन्दरी । वारमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ शर्मदा शाङ्करी सीता रवीन्दुशिखिलोचना । मदिरा वारुणी वीणा गीतज्ञा मदिरावती ॥ वटस्था वारुणी मुक्तिर्वटजा वटवासिनी ।

चट्टकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी चमूः ॥ मुद्गराङ्कुशह-
स्ताढ्या वराभयकरा क्रुटी। पाटीरद्रुमवल्ली च वटिका वटुके-
श्वरी। इष्टदा कृपिभूः कीटी रेवतीरमणप्रिया। रोहिणी रेवती
रम्या रमणा रोमहर्षिणी ॥ रसोल्लासा रसासारा सारिणी तां-
रिणी तडित् ॥ तरी अरित्रहस्ता च तोतुला तरणिप्रभा। रत्ना-
करप्रिया रम्भा रत्नालङ्कारशोभिता। रुक्माङ्गदा गदाहस्ता ग-
दाधरवरप्रदा। षड्रसा द्विरसा माला मालाभरणभूषिता ॥ मा-
लती मल्लिकामोदा मोदकाहारवल्लभा। वल्लरी मधुरा माया
काशी काञ्ची अवन्तिका ॥ हसन्तिका हसन्ती च भ्रामरी च
वसन्तिका। क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा क्षणेश्वरी ॥ क्ष-
णदा क्षेमदा सीरा सीरपाणिसमर्चिता। क्रीता क्रीतातपा क्रूरा
कमनीया कुलेश्वरी ॥ कूर्चबीजा कुठाराढ्या कूर्मिणी कूर्मसु-
न्दरी। कारुण्या चैव काश्मीरी दूती द्वारवती ध्रुवा ॥
ध्रुवस्तुता द्रुतगतिः पीठेशी वगलामुखी। सुमुखी शोभ-
नाऽनेकरता ज्वालामुखी द्युतिः ॥ अलकोज्जयिनी भोग्या
भङ्ग्या भोगवती बला। धर्मराजपुरी पूर्णा पूर्णसत्वाऽम-
रावती ॥ अयोध्या योधनीया च युगमाता च यक्षिणी।
यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी ॥ यशोवती च
शोभाङ्गी चारुहासा चलाचला। हरेश्वरी हरेर्माया मायिनी
वायुवेगिनी ॥ अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः।
कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी ॥ कठोरवाक्
कुहूमूर्तिश्चन्द्रबिम्बसमानना। चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचल-
वासिनी ॥ मलयाचलसानुस्था हिमाद्रितनया तनुः। हिमाद्रि-

कुक्षिदेशस्था कुब्जिका कोसलेश्वरी ॥ कारैकनिगडा गूढा गूढ-
गुल्फाऽतिगोपिता । तनुजा तनुरूपा च चापबाणधरा नुतिः ।
धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना । अरुणेशी रतिः स्वा-
तिर्गरिष्ठा च गरीयसी ॥ महानसी महाकारा सुरासुरभयंकरी ।
अणुरूपा बृहज्ज्योतिरनिरुद्धा सरस्वती ॥ श्यामा श्याममुखी
शान्ता शान्तसन्तापहारिणी । गौर्गुण्या गोमयी गुह्या गोमती गु-
रुर्वाक् गतिः ॥ गीतसन्तोषसंसक्ता ग्राहिणी ग्रहिणी गुहा । गण-
प्रिया गजगतिर्गान्धारी गन्धमोदिनी ॥ गन्धमादनसानुस्था स-
ह्याचलकृतालया । गजाननप्रिया गव्या ग्रामिका ग्राहवाहना ॥
गुहप्रसूर्गुहावासा ग्रहमालाविभूषणा । कावेरी कुहकभ्रान्तिस्तर्क-
विद्या प्रियङ्करी । पीताम्बरा पटाकारा पताका सृष्टिदा सुधा ॥
दाक्षायणी दक्षसुता दक्षयज्ञविनाशिनी । ताराचक्रस्थिता तारा
तुरी तुर्या तुटिस्तुला ॥ सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्य-
लालिता । ललिता लोहिता लुम्पा चम्पा कम्पा कुणस्रणिः ॥
ख्यातिः सत्यवती स्वस्था समानी मानवर्धिनी । मनोमयी मन-
स्तुष्टिः कामधेनुः सनातनी ॥ सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा
कलावती । तलातलाश्रया सिन्धुस्त्र्यम्बिका लम्बिका जया ॥
सौदामिनी महादेवी सनकर्षिसमर्चिता । मन्दाकिनी च
यमुना विपाशा नर्मदानदी ॥ गण्डकी रावनी सिप्रा वितस्ता
च सरस्वती । रेवा चैरावती चेक्षुमती सागरवासिनी ॥
देवकी देवमाता च देवेशी देवसुन्दरी । दैत्यघ्नी दमनी दाता
दितिर्दितिजसुन्दरी ॥ विद्याधरी च विद्येशी विद्याधरजसु-
न्दरी । मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥

उर्वशी मोहिनी रम्भा अप्सरोगणसुन्दरी ॥ यक्षिणी यक्षलोकेशी नरवाहनपूजिता ॥ यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी । मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी । रक्षोहन्त्री केकसी च रक्षोनायकसुन्दरी ॥ किन्नरी कम्बुकण्ठी च कलकण्ठस्वना स्वधा । किंमुखी हयवक्त्रा च केला किन्नरसुन्दरी । पिशाची राजमातङ्गी चोच्छिष्टपदसंस्थिता । महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी । सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ भूतेश्वरी भूतलया भूतधात्री भयापहा । भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ पृथ्वी पार्थिवलोकेशी पृथा विष्णुसमर्चिता । वसुन्धरा वसुनता पृथिवी भूमिसुन्दरी ॥ अम्बोधितनया लुप्ता जलजाक्षी जलेश्वरी । अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ तेजस्विनी महोधात्री तेजस्वी सूर्यबिम्बगा । सूर्यकान्तिः सूर्यतेजास्तेजोरूपैकसुन्दरी ॥ वायुवाहा वायुमुखी वायुलोकैकसुन्दरी । गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ निराभासा भासमाना द्युतिराकाशसुन्दरी । क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ अब्धियाना रत्नशोभा वारुणेशी वरायुधा । पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ अतिलोकरुचिर्ज्योतिः पञ्चाननगतिस्थितिः । प्राणापानसमानेशा चोदानव्यानरूपिणी ॥ पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी । अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ हेतिर्हव्यहुतज्योतिरग्निजा वह्निसुन्दरी । सोमेश्वरी सोमकला सोमपानपरायणा ॥ सौम्यानना

सौम्यरूपा सोमस्था सोमसुन्दरी । सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्य-
सुन्दरी ॥ याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा । याजकी यज्ञ-
विद्या च यजमानैकसुन्दरी ॥ आकाशगामिनी वन्द्या शब्दजाऽ-
काशसुन्दरी । मीनप्रिया मीननेत्रा मीनेशा मीनसुन्दरी ॥ कूर्म-
पृष्ठगता कूर्मी कूर्मजा कूर्मरूपिणी । वाराही वीरसूर्वेद्या वरारोहा
मृगेक्षणा ॥ वराहमूर्तिर्वाचाला दंष्ट्रा वाराहसुन्दरी । नरसिं-
हाकृतिर्देवी दुष्टदैत्यनिषूदना ॥ प्रद्युम्नवरदा नारी नारसिंहैक-
सुन्दरी । वामजा वामनाकारा नारायणपरायणा ॥ बलिदान-
वदर्पघ्नी वामा वामनसुन्दरी । रामप्रिया रामकीला क्षत्रवंश-
क्षयङ्करी ॥ धर्मपुत्री राजकन्या रामा परशुधारिणी । भार्गवी
भार्गवेष्टा च जमदग्निवरप्रदा । कुठारधारिणी रात्रिर्जामदग्न्यै-
कसुन्दरी । सीता लक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ राम-
प्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा । लावण्यामृतधाराढ्या लव-
णासुरघातिनी ॥ लोहितास्या प्रसन्नास्या सुरामा रामसुन्दरी ।
कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ यादोगणार्चिता
योग्या राधा श्रीकृष्णसुन्दरी । बुद्धप्रसूर्बुद्धदेवी जिनमार्गपरा-
यणा ॥ जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया । जिन-
वंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ काली कोलाहलप्रीता
प्रेतवाहा पुरेश्वरी । कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ।
विष्णुमाया ब्रह्ममाया शाम्भवी शववाहना ॥ इन्द्रावरजवक्त्रस्था
स्थाणुपत्नी पलालिनी । जृम्भिनी जृम्भहर्त्री च लम्बमानकचाऽ-
कुला ॥ कुलाकुलपदेशानी पददानफलप्रदा । कुलवागीश्वरी
कुल्या कुलजा कुलसुन्दरी ॥ पुरन्दरेष्टा कारुण्यालया पुण्यजने-

श्वरी ॥ पुण्योत्साहा पापहर्त्री पाकशासनसुन्दरी ॥ सूर्यकोटि-
प्रतीकाशा सूर्यतेजोमयी मषी । लेखनी आजिता रज्जुरूपिणी
सूर्यसुन्दरी ॥ चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ।
लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् ॥ सहस्रशीर्षा
चन्द्राक्षी सहस्रभुजवल्लिका । कोटिरत्नांशुशोभाढ्या शुभ्रवस्त्रा
शतानना ॥ शतानन्दा श्रुतिधरा पिङ्गलेडोग्रनादिनी । सुषुम्णा
हारकेयूरनूपुरारावसंकुला ॥ घोरनादा घोरमुखी चोन्मुखी
चोल्मुकायुधा । गोपिता गुर्जरी गाथा गायत्री वेदवल्लभा ॥
वल्लकी सुरनादा च नादविद्या नदीतटी । विन्दुरूपा चक्रयो-
निर्बिन्दुनादस्वरूपिणी ॥ चक्रेश्वरी भैरवेशी महाभैरववल्लभा ।
कालभैरववल्या च कल्पान्तरङ्गनर्तकी ॥ प्रलयानलधूम्राभा
योनिमध्यकृतालया । भूचरीखेचरीमुद्रा नवमुद्राविलासिनी ॥
वियोगिनी श्मशानस्था श्मशानार्चनतोषिता । भास्वराङ्गी
भर्गशिखा भर्गवामाङ्गवासिनी ॥ भद्रकाली विश्वकाली श्रीकाली
मेघकालिका । नीलकाली कालरात्रिः काली कामेशकालिका ॥
इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका । श्मशानकालिका
श्रींह्रींकाली श्रीकृष्णकालिका ॥ क्रींकारोत्तरकाली श्रींहुंह्रींद-
क्षिणकालिका । सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता ॥
त्रिनेत्रा त्रिपुराध्यक्षा त्रिपुटा पुटभैरवी । त्रिलोकजननी त्रेता
महात्रिपुरसुन्दरी ॥ कामेश्वरी कामकला कालकामेशसुन्दरी ।
द्व्यक्षरी त्र्यक्षरीदेवी भावना भुवनेश्वरी ॥ एकाक्षरी चतुष्कूटा
त्रिकूटेशी लयेश्वरी । चतुर्वर्णा चतुर्वेशी वर्णाढ्या चतुरक्षरी ॥
पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी । सप्ताक्षरी नवीनीवी

परमाष्टाक्षरीश्वरी ॥ नवमी पञ्चमी षष्टी नागेशी च नवाक्षरी। दशाक्षरी दशास्येशी देविकैकादशाक्षरी ॥ द्वादशादित्यसंकाशा द्वादशी द्वादशाक्षरी । त्रयोदशी वेदगर्भा वाद्या त्रयोदशाक्षरी ॥ चतुर्दशाक्षरीविद्या विद्या पञ्चदशाक्षरी । षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी ॥ महाश्रीषोडशीविद्या चिन्तामणिमनुप्रिया। द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी ॥ वज्रतारा कालतारा नारीतारोग्रतारिणी । कामतारा शब्दतारा शब्दतारा रसाश्रया ॥ रूपतारा गन्धतारा महानीलसरस्वती । कामज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला ॥ विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी । विकरालमुखी देवी कराली भूतिभूषणा ॥ चिता शवासना चिन्ता चितामण्डलमध्यगा । भूतभैरवसेव्या च भूतभैरवपालिनी ॥ बन्धकी बद्धसम्बन्धा भवबन्धविनाशिनी । भवानी देवदेवेशी दीक्षा दीक्षितपूजिता ॥ साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी । साधकाश्रयभूता च साधकेष्टफलप्रदा ॥ रजोवती राजसी च रजकी च रजस्वला । पुष्पप्रिया पुष्पवती स्वयम्भूः पुष्पमालिका ॥ स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतघातिनी । पात्रहस्ता सुरापात्रार्पिताशा पीतभूषणा ॥ पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी । मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला ॥ पुरूरवेश्वरी पाशधरा चापधराऽध्वरा । पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी ॥ होतृसेव्या हकारस्था मकारस्था सुखावहा । सुखी शोभावती सत्या सत्याचारपरायणा ॥ सत्यार्चना कुलेशानी वासुदेवकलाश्रया । सद्योजातकलादेवी शिवा घोरकलाकृतिः ॥ शर्वरी

क्षीरसदृशी क्षीरनीरविवेकिनी । वितर्कनिलया नित्यां नित्य-क्लिन्ना पराम्बिका ॥ पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी । काशिका कौशिकी कोशी कोशदां रूपवर्धिनी ॥ तुष्टिः पुष्टिः प्रजा प्रीता पूजिका पूजकप्रिया । प्रजावती गर्भवती गर्भपोषणपोषितां । शुक्लवासाः शुक्लरूपा शुचिहासा जयावहा । जानकी जन्यजनका जनतोषणतत्परा ॥ वादप्रिया वाद्यरता वन्दितां वातसुन्दरी । वाक्स्तम्भिनी कीरवाणी धीरा धीरधुरन्धरी ॥ स्तनन्धयी सामधेनी निरानन्दा निरालया । समस्तसुखदां शारी वारांनिधिवरप्रदा ॥ वालुकी वीरपानेष्टा वसुदात्री वसुप्रिया । शुक्रानन्दा शुक्ररसा शुक्रपूज्या शुकप्रियां ॥ शुकी च शुकहस्ता च समस्तनरकान्तका । समस्ततत्त्वनिलया भगरूपा भगेश्वरी ॥ भगबिम्बा भगा हृद्या भगलिङ्गस्वरूपिणी । भगलिङ्गेश्वरी श्रीदा भगलिङ्गाऽमृतस्रवा ॥ क्षीराशना क्षीररुचिराऽज्यपानपरायणा । मधुपानपरा प्रौढा पीवरांसा परम्परां ॥ पिलम्पिला पटोलेशा पाटलाऽरुणलोचना । क्षीराम्बुधिप्रिया क्षीवा सरला सरलायुधा ॥ सङ्ग्रामा सुनयां स्रस्ता संसृतिः सनकेश्वरी । कन्या कनकलेखा च कान्यकुब्जनिवासिनी ॥ काञ्चनाभतनुः काष्ठा कुष्ठरोगविनाशिनी । कठोरमूर्धजा कुन्ती कुन्तायुधधरा धृतिः ॥ चर्माम्बरा क्रूरनखी कठोराक्षी चतुर्भुजा । चतुर्वेदप्रिया चर्या चतुर्वर्गफलप्रदां ॥ ब्रह्माण्डचारिणी स्फूर्तिर्ब्रह्माणी ब्रह्मसंमिता । सत्कारकारिणी मूर्तिः स्तृतिका लतिका लता ॥ कल्पवल्ली कृशाङ्गी च कल्पपादपवासिनी । कल्पपाशा महाविद्या विद्याराज्ञी सुखाश्रया ॥ भूतराज्ञी विश्व-

राज्ञी लोकराज्ञी शिवाश्रयाँ । ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया ॥ नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया । सत्त्व-
१०००
राज्ञी तमोराज्ञी गुणराज्ञी चलाचला । वसुराज्ञी सत्यराज्ञी तपोराज्ञी जयप्रिया । मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रियाँ । देवराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा । कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया ॥ गजराज्ञी गदाराँज्ञी गणराज्ञी गुणाश्रया । पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ सुराराज्ञी सुधा-राज्ञी भीमराज्ञी भयोज्झितांँ । तथ्यराज्ञी जयाराज्ञी महाराज्ञी कुलाकृतिः ॥ वामराज्ञी चैनराज्ञी हलिराज्ञी हलेश्वरी । परा-राज्ञी यक्षराँज्ञी भूतराज्ञी शवासना ॥ वटुराज्ञी प्रेतराज्ञी शेष-राज्ञी शमप्रदा । आकाशराज्ञी राज्येशी राज्यराज्ञी रतिप्रियाँ ॥ पातालराज्ञी भूराज्ञी प्रेमराज्ञी विषापहा । सिद्धराज्ञी विभा-राज्ञी ज्योतीराज्ञी विभास्वरी ॥ भास्वद्राज्ञी चन्द्रराँज्ञी तारा-राज्ञी खवासिनी । ग्रहराज्ञी लताराज्ञी वृक्षराज्ञी मतिप्रदा ॥ धीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यँपी । मुनिराज्ञी रत्नराज्ञी युगराज्ञी मणिप्रभा ॥ सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरी-स्थितिः । बिन्दुराज्ञी नादँराज्ञी त्वात्मराज्ञी च सद्गतिः । पुत्र-राज्ञी ध्यानराज्ञी जयराज्ञी सदेश्वरी । ईशानराज्ञी राज्ञीशी स्वाहाराज्ञी महत्तराँ ॥ वह्निराज्ञी योगराज्ञी यज्ञराज्ञी चिदाकृतिः । जगद्राज्ञी तत्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ पञ्चदशाक्षरी राज्ञी ॐह्रींभूतेश्वरीश्वरी ॥ इति नामस्तोत्रम् ॥ अथ नामावली ॥

ॐह्रींश्रींरांमहाराज्ञ्यै स्वाहा, क्लींसौःपञ्चादशाक्षर्यैह्रीं स्वाहा, त्र्यक्षरीविद्यायै, पराभगवत्यै, विभायै, भास्वत्यै, भद्रि-

कायै, भीमायै, भर्गरूपायै, महस्विन्यै, माननीयायै, मनीषायै, मनोजायै, मनोजवायै, मानदायै, मन्त्रविद्यायै, महाविद्यायै, षडक्षर्यै, षट्कूटायै, त्रिकूटायै, त्रय्यै, वेदत्रय्यै, शिवायै, शिवाकारायै, विरूपाक्ष्यै, शशिखण्डावतंसिन्यै, महालक्ष्म्यै, महोरस्कायै, महौजस्कायै, महोदर्यै, मातङ्ग्यै, मोदकाहारायै, मदिरारुणलोचनायै, साध्व्यै, शीलवत्यै, शालायै, सुधाकलशधारिण्यै, खड्गिन्यै, पद्मिन्यै, पद्मायै, पद्मकिञ्जल्करञ्जितायै, हृत्पद्मवासिन्यै, हृद्यायै, पानपात्रधरायै, धरायै, धराधरेन्द्रतनयायै, दक्षिणायै, दक्षजायै, दयायै, दयावत्यै, महामेधायै, मेदिन्यै, बोधिन्यै, गदायै, गदाधरार्चितायै, गोधायै, गङ्गायै, गोदावर्यै, गयायै, महाप्रभावसहितायै, महोरगविभूषणायै, महामुनिकृतातिथ्यायै, माध्व्यै, मानवत्यै, मघायै, बालायै, सरस्वत्यै, लक्ष्म्यै, दुर्गायै, दुर्गतिनाशिन्यै, शार्यै, शरीरमध्यस्थायै, वैखर्यै, खेचरीश्वर्यै, शिवदायै, शिववक्षःस्थायै, कालिकायै, त्रिपुरायै, पुर्यै, पुरारिकुक्षिमध्यस्थायै, मुरारिहृदयेश्वर्यै, बलारिराज्यदायै, चण्ड्यै, चामुण्डायै, मुण्डधारिण्यै, मुण्डमालाञ्चितायै, मुद्रायै, क्षोभदायै, कर्षणक्षमायै, ब्राह्म्यै, नारायणीदेव्यै, कौमार्यै, अपराजितायै, रुद्राण्यै, शच्यै, इन्द्राण्यै, वाराह्यै, वीरसुन्दर्यै, नारसिंह्यै "तेजोसि" भैरवेश्यै स्वाहा ॥ ध्यानं ॥ भैरवाकारभीषणायै, नागालङ्कारशोभाढ्यायै, नागयज्ञोपवीतिन्यै, नागकङ्कणकेयूरायै, नागहारायै, सुरेश्वर्यै, सुरारिघातिन्यै, पूतायै, पूतनायै, डाकिन्यै क्रियायै, क्रियावत्यै, कुर्यै, कृत्यायै,

शाकिन्यै, हाकिन्यै, लयायै, लीलावत्यै, रसाकीर्णायै, नागकन्यायै, मनोहरायै, हारकङ्कणशोभाढ्यायै, सदानन्दायै, शुभङ्कर्यै, प्रहासिन्यै, मधुमत्यै, सरश्रियै, सरमोहिन्यै, महोग्रवपुष्यै, वार्तायै, वामाचारप्रियायै, सिरायै, सुधामय्यै, वेणुकरायै, वैरहायै, वामसुन्दर्यै, वारमध्यस्थितायै, वामायै, वामनेत्रायै, शशिप्रभायै, शर्मदायै, शाङ्कर्यै, सीतायै, रवीन्दुशिखिलोचनायै, मदिरायै, वारुण्यै, वीणायै, गीतज्ञायै, मदिरावत्यै, वटस्थायै, वारुण्यै, सूक्तये, वटुजायै, वटुवासिन्यै, वटुक्यै, वीरसुवे, वन्ध्यायै, स्तम्भिन्यै, मोहिन्यै, चम्वै, मुद्गराङ्कुशहस्तायै, ईड्यायै, वराभयकरायै, कुट्यै, पाटीरद्रुमवह्न्यै, वटिकायै, वटुकेश्वर्यै, इष्टदायै, कृषिभुवे, कीट्यै, रेवतीरमणप्रियायै, रोहिण्यै, रेवत्यै, रम्यायै, रमणायै, रोमहर्षिण्यै, रसोल्लासायै, रसासारायै, सारिण्यै, तारिण्यै, तडिते, तर्यै, अरित्रहस्तायै, तोतुलायै, तरणिप्रभायै, रत्नाकरप्रियायै, रम्भायै, रत्नालङ्कारशोभितायै, रुक्माङ्गदायै, गदाहस्तायै, गदाधरवरप्रदायै, षड्रसायै, द्विरसायै, मालायै, मालाभरणभूषितायै, मालत्यै, मल्लिकामोदायै, मोदकाहारवल्लभायै, वल्ल्यै, मधुरायै, "तेजोसि" मायायै, स्वाहा २००

॥ ध्यानं ॥ काश्यै, काञ्च्यै, अवन्तिकायै, हसन्तिकायै, हसन्त्यै, भ्रामर्यै, वसन्तिकायै, क्षेमायै, क्षेमङ्कर्यै, क्षामायै, क्षौमवस्त्रायै, क्षणेश्वर्यै, क्षणदायै, क्षेमदायै, सीरायै, सीरपाणिसमर्चितायै, क्रीतायै, क्रीतातपायै, क्रूरायै, कमनीयायै, कुलेश्वर्यै, कूर्चबीजायै, कुठाराढ्यायै, कूर्मिण्यै, कूर्मसुन्दर्यै, कारुण्यायै, काश्मीर्यै, दूत्यै, द्वारवत्यै, ध्रुवायै, ध्रुवस्तुतायै, ध्रुवगतये, पी-

ठेश्यै, बगलामुख्यै, सुमुख्यै, शोभनायै, अनेकरत्नायै, ज्वाला-मुख्यै, नुतये, अलकाँयै, उज्जयिन्यै, भोग्यायै, भंग्यायै, भोग-वत्यै, बलायै, धर्मराजपुर्यै, पूर्णायै, पूर्णसत्वायै, अमरावत्यै, अयोध्यांयै, योधिनीयायै, युगमात्रे, यक्षिण्यै, यज्ञेश्वर्यै, योगग-म्यायै, योगिध्येयायै, यशस्विन्यै, यशोवत्यै, शोभाङ्ग्यै, चारु-हासाँयै, चलाचलायै, हरेश्वर्यै, हरेर्मायायै, मायिन्यै, वायु-वेगिन्यै, अम्बालिकायै, अम्बायै, भर्गेश्यै, भृगुकूटायै, महा-मँतये, कोशेश्वर्यै, कमलायै, कीर्तिदायै, कीर्तिवर्धिन्यै, कठोर-वाचे, कुहूमूर्तये, चन्द्रविम्बसमाननायै, चन्द्रकुङ्कुमलिप्ताङ्ग्यै, कनकाचलवासिन्यै, मलयाचलँसानुस्थायै, हिमाद्रितनयायै, तन्वे, हिमाद्रिकुक्षिदेशस्थायै, कुब्जिकायै, कोसलेश्वर्यै, कारैकनि-गडायै, गूढायै, गूढगुल्फायै, अतिगोपितायै, तनुजायै, तनुरू-पायै, चापबाणधरायै, नुतये, धुरीणायै, धूम्रवाराह्यै, धूम्रके-शायै, अरुणाननायै, अरुणेश्यै, रतये, "तेजोसि" स्वात्यै स्वाहा २०० ॥ ध्यानं ॥ गरिष्ठायै, गरीयस्यै, महानस्यै, महाकारायै, सुरासुरभयङ्कर्यै, अणुरूपायै, बृहज्ज्योतिषे, अनिरुद्धायै, सर-स्वत्यै, श्यांमायै, श्याममुख्यै, शान्तायै, शान्तसन्तापहारिण्यै, गवे, गुण्यायै, गोमय्यै, गुह्यायै, गोमत्यै, गुरुवाचे, गतये, गीतसन्तोषसंसक्तायै, ग्राहिण्यै, ग्रहिण्यै, गुहायै, गणप्रियायै, गजगतये, गान्धार्यै, गन्धमोदिन्यै, गन्धमादनसानुस्थायै, सह्याचलकृतालयाँयै, गजाननप्रियायै, गव्यायै, ग्रामिकायै, ग्राहवाहनायै, गुहप्रस्वै, गुहावासायै, ग्रहमालाविभूषणायै, का-वीर्यै, कुहकभ्रान्त्यै, तर्कविद्यांयै, प्रियङ्कर्यै, पीताम्बरायै, पटा-

कारायै, पताकायै, सृष्टिदायै, सुधायै, दाक्षायण्यै, दक्षसुतायै, दक्षयज्ञविनाशिन्यै, ताराचक्रस्थितायै, तारायै, तुर्यै, तुर्यायै, तुट्यै, तुलायै, सन्ध्यात्रय्यै, सन्धिजरायै, सन्ध्यायै, तारण्यललितायै, ललितायै, लोहितायै, लुम्पायै, चम्पायै, कम्पायै, कुणस्तृणये, स्तये, सत्यवत्यै, स्वस्थायै, समानायै, मानवर्धिन्यै, मनोमय्यै, मनस्तुष्ट्यै, कामधेन्वै, सनातन्यै, सूक्ष्मरूपायै, सूक्ष्ममुख्यै, स्थूलरूपायै, कलावत्यै, तलातलाश्रयायै, सिन्धवे, त्र्यम्बिकायै, लम्बिकायै, जयायै, सौदामिन्यै, महादेव्यै, सनकर्षिसमर्चितायै, मन्दाकिन्यै, यमुनायै, विपाशायै, नर्मदानद्यै, गण्डक्यै, इरावत्यै, सिप्रायै, वितस्तायै, सरस्वत्यै, रेवायै, ऐरावत्यै, इक्षुमत्यै, सागरवासिन्यै, "तेजोऽसि" देवक्यै, स्वाहा ॥ ४०० । ध्यानं ॥ देवमात्रे, देवेश्यै, देवसुन्दर्यै, दैत्यघ्न्यै, दमन्यै, दात्रे, दित्यै, दितिजसुन्दर्यै, विद्याधर्यै, विद्येश्यै, विद्याधरजसुन्दर्यै, मेनकायै, चित्रलेखायै, चित्रिण्यै, तिलोत्तमायै, उर्वश्यै, मोहिन्यै, रम्भायै, अप्सरोगणसुन्दर्यै, यक्षिण्यै, यक्षलोकेश्यै, नरवाहनपूजितायै, यक्षेन्द्रतनयायै, योग्यायै, यक्षनायकसुन्दर्यै, मन्दोदर्यै, करालाक्ष्यै, मेघनादवरप्रदायै, मेघवाहनसन्तुष्टायै, मेघमूर्तये, राक्षस्यै, रक्षोहन्त्रे, केकस्यै, रक्षोनायकसुन्दर्यै, किन्नर्यै, कम्बुकण्ठ्यै, कलकण्ठसुनायै, स्वधायै, किंपुरुष्यै, हयवक्त्रायै, केलायै, किन्नरीसुन्दर्यै, पिशाच्यै, राजमातङ्ग्यै, उच्छिष्टपदसंस्थितायै, महापिशाचिन्यै, चान्द्र्यै, पिशाचकुलसुन्दर्यै, गुह्येश्वर्यै, गुह्यरूपायै, गुह्यै, गुह्यकसुन्दर्यै, सिद्धिप्रदायै, सिद्धवध्वै, सिद्धेश्यै, सिद्ध-

सुन्दर्यै, भूतेश्वर्यै, भूतलयायै, भूतधात्र्यै, भयापहायै, भूतभीतिहर्यै, भव्यायै, भूतजायै, भूतसुन्दर्यै, पृथ्व्यै, पार्थिवलोकेश्यै, पृथायै, विष्णुसमर्चितायै, वसुन्धरायै, वसुनतांयै, पृथिव्यै, भूमिसुन्दर्यै, अम्भोधितनयायै, लुप्तायै, जलजाक्ष्यै, जलेश्वर्यै, अमूर्तये, अम्मय्यै, मायै, जलस्थांयै, जलसुन्दर्यै, तेजस्विन्यै, महोधात्र्यै, तेजस्व्यै, सूर्यबिम्बगायै, सूर्यकान्तये, सूर्यतेजसे, तेजोरूपायै, एकसुन्दर्यै, वायुवाहांयै, वायुमुख्यै, वायुलोकैकसुन्दर्यै, गगनस्थायै, देवचारिण्यै, शून्यरूपायै, निराकृतये, निराभासायै, भासमानायै, द्युतये "तेजोसि" आकाशसुन्दर्यै स्वाहा ५०० । ध्यानम् ॥ ॐ क्षितिमूर्तिधरायै, अनन्तायै, क्षितिभृते, लोकसुन्दर्यै, अब्धियानायै, रत्नशोभायै, वारुणेश्यै, वरायुधायै, पाशहस्तायै, पोषणांयै, वरुणेश्वरसुन्दर्यै, अतिलोकरुचये, ज्योतिषे, पञ्चाननकृतस्थितये, प्राणापानसमानेशायै, उदानव्यानरूपिण्यै, पञ्चवातगतये, नाडीरूपिण्यै, वातसुन्दर्यै, अग्निरूपांयै, वह्निशिखायै, वाडवानलसन्निभायै, हेतये, हव्यहृतज्योतिषे, अग्निजायै, वह्निसुन्दर्यै, सोमेश्वर्यै, सोमकलायै, सोमपानपरायणायै, सौम्याननांयै, सौम्यरूपायै, सोमस्थायै, सोमसुन्दर्यै, सूर्यप्रभायै, सूर्यमुख्यै, सूर्यजायै, सूर्यसुन्दर्यै, याज्ञिक्यै, यज्ञभागेच्छायै, यजमानवरप्रदायै, याजक्यै, यज्ञविद्यायै, यजमानैकसुन्दर्यै, आकाशगामिन्यै, वन्द्यायै, शब्दजायै, आकाशसुन्दर्यै, मीनप्रियायै, मीननेत्रायै, मीनेशांयै, मीनसुन्दर्यै, कूर्मपृष्ठगतायै, कूर्म्यै, कूर्मजायै, कूर्मरूपिण्यै, वाराह्यै, वीरखै, वह्यायै, वरारोहायै, मृगेक्षणांयै, वराहमूर्त्तये, वाचालायै, दं-

ष्ट्रायै, वाराहसुन्दर्यै, नारसिंहाकृतये, देव्यै, दुष्टदैत्यनिषूदनायै, प्रद्युम्नवरदायै, नार्यै, नारसिंहैकसुन्दर्यै, वामजायै, वामनायै, कारायै, नारायणपरायणायै, बलिदानवदर्पघ्न्यै, वामायै, वामनसुन्दर्यै, रामप्रियायै, रामकीलायै, क्षत्रवंशक्षयङ्कर्यै, धनपुत्र्यै, राजकन्यायै, रामायै, परशुधारिण्यै, भार्गव्यै, भार्गवेष्टायै, जमदग्निवरप्रदायै, कुठारधारिण्यै, रात्र्यै, जामदग्न्यैकसुन्दर्यै, सीतायै, लक्ष्मणसेव्यायै, रक्षःकुलविनाशिन्यै, रामप्रियायै, शत्रुघ्न्यै, शत्रुघ्नभरतेष्टदायै, लावण्यामृतधाराढ्यायै, लवणासुरघातिन्यै, लोहितास्यायै, "तेजोऽसि" प्रसन्नास्यायै स्वाहा ६०० ॥ ध्यानम् ॥ सुरामायै, रामसुन्दर्यै, कृष्णकेशायै, कृष्णमुख्यै, यादवान्तकर्यै, लयायै, यादोगणार्चितायै, योग्यायै, राधायै, श्रीकृष्णसुन्दर्यै, बुद्धप्रस्वै, बुद्धदेव्यै, जिनमार्गपरायणायै, जितक्रोधायै, जितालस्यायै, जिनसेव्यायै, जितेन्द्रियायै, जिनवंशधरायै, उग्रायै, नीलान्तायै, बुद्धसुन्दर्यै, काल्यै, कोलाहलप्रीतायै, प्रेतवाहायै, पुरीश्वर्यै, कल्किप्रियायै, कम्बुधरायै, कलिकालैकसुन्दर्यै, विष्णुमायायै, ब्रह्ममायायै, शाम्भव्यै, शववाहनायै, इन्द्रावरजवक्षःस्थायै, स्थाणुपत्न्यै, पलालिन्यै, जृम्भिन्यै, जृम्भहन्त्र्यै, लम्बमानकचाकुलायै, कुलाकुलपदेशान्यै, पददानफलप्रदायै, कुलवागीश्वर्यै, कुल्यायै, कुलजायै, कुलसुन्दर्यै, पुरन्दरेष्टायै, कारुण्यालयायै, पुण्यजनेश्वर्यै, पुण्योत्साहायै, पापहन्त्र्यै, पाकशासनसुन्दर्यै, सूर्यकोटिप्रतीकाशायै, सूर्यतेजोमय्यै, मण्यै, लेखन्यै, भ्राजितायै, रज्जुरूपिण्यै, सूर्यसुन्दर्यै, चन्द्रिकायै, सुधाधारायै, ज्योत्स्नायै, शीतांशुसुन्दर्यै, लोला-

क्ष्यै, शताक्ष्यै, सहस्राक्ष्यै, सहस्रपादे, सहस्रशीर्षायै, चन्द्राक्ष्यै, सहस्रभुजवल्लिकायै, कोटिरत्नांशुशोभाढ्यायै, शुभ्रवस्त्रायै, शताननायै, शतानन्दायै, श्रुतिधरायै, पिङ्गलायै, इडायै, उग्रनादिन्यै, सुषुम्णायै, हारकेयूरनूपुरारवसंकुलायै, घोरनादायै, घोरमुख्यै, उन्मुख्यै, उल्मुकायुधायै, गोपितायै, गूर्जर्यै, गाथायै, गायत्र्यै, वेदवल्लभायै, वल्लक्यै, सुरनादायै, नादविद्यायै, नदीतट्यै, बिन्दुरूपायै, चक्रयोनये, बिन्दुनादस्वरूपिण्यै, चक्रेश्वर्यै, भैरवेश्यै, महाभैरववल्लभायै, कालभैरववल्लयायै, कल्पान्तरङ्गनर्तक्यै, "तेजोसि" प्रलयानलधूम्राभायै, स्वाहा ७०० ॥

ध्यानं ॥ योनिमध्यकृतालयायै, भूचरीखेचरीमुद्रायै, नवमुद्राविलासिन्यै, वियोगिन्यै, श्मशानस्थायै, श्मशानार्चनतोषितायै, भास्वराङ्ग्यै, भर्गशिखायै, भर्गवामाङ्गवासिन्यै, भद्रकाल्यै, विश्वकाल्यै, श्रीकाल्यै, मेघकालिकायै, नीलकाल्यै, कालरात्र्यै, काल्यै, कामेशकालिकायै, इन्द्रकाल्यै, पूर्वकाल्यै, पश्चिमाम्नायकालिकायै, श्मशानकालिकायै, श्रींह्रींकाल्यै, श्रींकृष्णकालिकायै, क्रींकारोत्तरकाल्यै, श्रींहुंह्रींदक्षिणकालिकायै, सुन्दर्यै, त्रिपुरेशान्यै, त्रिकूटायै, त्रिपुरार्चितायै, त्रिनेत्रायै, त्रिपुराध्यक्षायै, त्रिपुटायै, पुटभैरव्यै, त्रिलोकजनन्यै, त्रेतायै, महात्रिपुरसुन्दर्यै, कामेश्वर्यै, कामकलायै, कालकामेशसुन्दर्यै, ह्र्यक्षर्यै, त्र्यक्षरीदेव्यै, भावनायै, भुवनेश्वर्यै, एकाक्षर्यै, चतुष्कूटायै, त्रिकूटेश्यै, लयेश्वर्यै, चतुर्वर्णायै, चतुर्वेश्यै, वर्णाढ्यायै, चतुरक्षर्यै, पञ्चाक्षर्यै, षड्वक्रायै, षट्कूटायै, षडक्षर्यै, सप्ताक्षर्यै, नवीनीव्यै, परमाष्टाक्षरीश्वर्यै, नवम्यै, पञ्चम्यै, षष्ठ्यै, नागेश्यै, नवाक्षर्यै,

दशाक्षर्यै, दशास्यै, देविकायै, एकादशाक्षर्यै, द्वादशादित्य-सङ्काशायै, द्वादश्यै, द्वादशांक्षर्यै, त्रयोदश्यै, वेदगर्भायै, वाद्यायै, त्रयोदशाक्षर्यै, चतुर्दशाक्षरीविद्यायै, पञ्चदशाक्षरीविद्यायै, षोडशीविद्यायै, सर्वविद्येश्यै, महाश्रीषोडशाक्षर्यै, महाश्रीषोडशीविद्यायै, चिन्तामणिमनुप्रियायै, द्वाविंशत्यक्षर्यै, श्यामायै, महाकालकुटुम्बिन्यै, वज्रतारायै, कालतारायै, नारीतारायै, उग्रतारिण्यै, कामतारायै, शब्दतारायै, शब्दताररसाश्रयायै, रूपतारायै, गन्धतारायै, महानीलायै, सरस्वत्यै, कामज्वालायै, वह्निज्वालायै, ब्रह्मज्वालायै, जटाकुलायै, "तेजोसि" ॐविष्णुज्वालायै, स्वाहा॥ ८०० ॥ ध्यानं ॥ ॐजिष्णुशिखायै, भद्रज्वालायै, करालिन्यै, विकरालमुखीदेव्यै, कराल्यै, भूतिभूषणायै, चितायै, शवासनायै, चिन्तायै, चिन्तामण्डलमध्यगायै, भूतभैरवसेव्यायै, भूतभैरवपालिन्यै, बन्धक्यै, बद्धसम्बन्धायै, भवबन्धविनाशिन्यै, भवान्यै, देवदेवेश्यै, दीक्षायै, दीक्षितपूजितायै, साधकेश्यै, सिद्धिदात्र्यै, साधकानन्दवर्धिन्यै, साधकाश्रयभूतायै, साधकेष्टफलप्रदायै, रजोवत्यै, राजस्यै, रजक्यै, रजस्वलायै, पुष्पप्रियायै, पुष्पवत्यै, स्वयम्भुवे, पुष्पमालिकायै, स्वयम्भूपुष्पगन्धाढ्यायै, पुलस्त्यसुतघातिन्यै, पात्रहस्तायै, सुरापात्रार्पिताशायै, पीतभूषणायै, पिङ्गाननायै, पिङ्गकेश्यै, पिङ्गलायै, पिङ्गलेश्वर्यै, मङ्गलायै, मङ्गलेशान्यै, सर्वमङ्गलमङ्गलायै, पुरूरवेश्वर्यै, पाशधरायै, चापधरायै, अध्वरायै, पुण्यधात्र्यै, पुण्यमय्यै, पुण्यलोकनिवासिन्यै, होतृसेव्यायै, हकारस्थायै, मकारस्थायै, सुखावहायै, सुख्यै, शोभावत्यै, सत्यायै, सत्या-

चारपरायणायै, सत्यार्चनायै, कुलेशान्यै, वामदेवकलाश्रयायै, सद्योजातकलादेव्यै, शिवायै, घोरकलाकृत्यै, शर्वर्यै, क्षीरसदृश्यै, क्षीरनीरविवेकिन्यै, वितर्कनिलयायै, नित्यायै, नित्यक्लिन्नायै, पराम्बिकायै, पुरारिदयितायै, दीर्घायै, दीर्घनासायै, अल्पभाषिण्यै, काशिकायै, कौशिक्यै, कोश्यै, कोशदायै, रूपवर्धिन्यै, तुष्ट्यै, पुष्ट्यै, प्रजायै, प्रीतायै, पूजकायै, पूजकप्रियायै, प्रजावत्यै, गर्भवत्यै, गर्भपोषणपोषितायै, शुक्लवाससे, शुक्लरूपायै, शुक्लहासायै, जयावहायै, जानक्यै, जन्यजनकायै, जनतोषणतत्परायै, वादप्रियायै, वाद्यरतायै, "तेजोसि" ॐवन्दितायैस्वाहा ॥ ९०० ॥ ध्यानं ॥ वातसुन्दर्यै, वाक्स्तम्भिन्यै, कीरवाण्यै, धीरायै, धीरधुरन्धर्यै, स्तनन्धय्यै, सामिधेन्यै, निरानन्दायै, निरामयायै, समस्तसुखदायै, शार्यै, वारांनिधिवरप्रदायै, वालुक्यै, वीरपानेष्टायै, वसुदात्र्यै, वसुप्रियायै, शुक्रानन्दायै, शुक्ररसायै, शुक्रपूज्यायै, शुक्रप्रियायै, शुक्यै, शुकहस्तायै, समस्तनरकान्तकायै, समस्ततत्त्वनिलयायै, भगरूपायै, भगेश्वर्यै, भगबिम्बायै, भगायै, हृद्यायै, भगलिङ्गस्वरूपिण्यै, भगलिङ्गेश्वर्यै, श्रीदायै, भगलिङ्गाऽमृतस्रवायै, क्षीराशनायै, क्षीररुचये, आज्यपानपरायणायै, मधुपानपरायै, प्रौढायै, पीवरांसायै, परम्परायै, पिलम्पिलायै, पटोलेशायै, पाटलायै, अरुणलोचनायै, क्षीराम्बुधिप्रियायै, क्षीवायै, सरलायै, सरलायुधायै, संग्रामायै, सुनयायै, स्रस्तायै, संसृतये, सनकेश्वर्यै, कन्यायै, कनकलेखायै, कान्यकुब्जनिवासिन्यै, काञ्चनाभतन्व्यै, काष्ठायै, कुष्ठरोगविनाशिन्यै, कठोरमूर्धजायै, कुन्त्यै, कुन्तायुधधरायै, धृत्यै,

चर्माम्बरायै, क्रूरनख्यै, कठोराक्ष्यै, चतुर्भुजायै, चतुर्वेदप्रियायै, चर्यायै, चतुर्वर्गफलप्रदायै, ब्रह्माण्डचारिण्यै, स्फूर्तये, ब्रह्माण्यै, ब्रह्मसंमितायै, सत्कारकारिण्यै, मूर्तये, सूतिकायै, लतिकायै, लतायै, कल्पवल्ल्यै, कृशांग्यै, कल्पपादपवासिन्यै, कल्पपाशायै, महाविद्यायै, विद्याराज्यै, सुखाश्रयायै, भूतराज्यै, विश्वराज्यै, लोकराज्यै, शिवाश्रयायै ब्रह्मराज्यै, विष्णुराज्यै, रुद्रराज्यै, जटाश्रयायै, नागराज्यै, वंशराज्यै, वीरराज्यै, रजःप्रियायै, सत्वराज्यै, "तेजोसि"। ॐतमोराज्यै स्वाहा ॥ १००० ॥ ध्यानं॥ गुणराज्यै, चलाचलायै, वसुराज्यै, सत्यराज्यै, तपोराज्यै, जपप्रियायै, मन्त्रराज्यै, वेदराज्यै, तन्त्रराज्यै, श्रुतिप्रियायै, देवराज्यै, मन्त्रिराज्यै, दैत्यराज्यै, दयाकरायै, कालराज्यै, प्रजाराज्यै, तेजोराज्यै, हराश्रयायै, गजराज्यै, गदाराज्यै, गणराज्यै, गुणाश्रयायै, पृथ्वीराज्यै, पयोराज्यै, वायुराज्यै, मदालसायै, सुराराज्यै, सुधाराज्यै, भीमराज्यै, भयोज्झितायै, तथ्यराज्यै, जयाराज्यै, महाराज्यै, कुलाकृतये, वामराज्यै, चैनराज्यै, हलिराज्यै, हलेश्वर्यै, पराराज्यै, यक्षराज्यै, भूतराज्यै, शवासनायै, वडराज्यै, प्रेतराज्यै, शेषराज्यै, शमप्रदायै, आकाशराज्यै, राज्येश्यै, राज्यराज्यै, रतिप्रियायै, पातालराज्यै, भूराज्यै, प्रेमराज्यै, विषापहायै, सिद्धराज्यै, विभाराज्यै, ज्योतीराज्यै, विभास्वर्यै, भास्वद्राज्यै, चन्द्रराज्यै, ताराराज्यै, खवासिन्यै, ग्रहराज्यै, लताराज्यै, वृक्षराज्यै, मतिप्रदायै, धीरराज्यै, मनोराज्यै, मनुराज्यै, काश्यप्यै, मुनिराज्यै, रत्नराज्यै, युगराज्यै, मणिप्रभायै, सिन्धुराज्यै, नदीराज्यै, नदराज्यै, दरीस्थितये,

बिन्दुराज्ञ्यै, नादराज्ञ्यै, आत्मराज्ञ्यै, सद्गतये, पुत्रराज्ञ्यै, ध्यानराज्ञ्यै, जयराज्ञ्यै, सदैश्वर्यै, ईशानराज्ञ्यै, राज्ञीज्ञ्यै, स्वाहाराज्ञ्यै, महत्तत्वराज्ञ्यै, वह्निराज्ञ्यै, योगराज्ञ्यै, यज्ञराज्ञ्यै, चिदाकृतये, जगद्राज्ञ्यै, तत्वराज्ञ्यै, वाग्राज्ञ्यै, विश्वरूपिण्यै, पञ्चदशाक्षरीराज्ञ्यै । तेजोसि ॥ ॐह्रींभूतेश्वरीश्वर्यैस्वाहा ११०० ॥ इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् । पञ्चदशाक्षरीतत्त्वं तत्त्वसारं मनुप्रियम् ॥ सर्वतत्त्वमयं पुण्यं महापातकनाशनम् । सर्वसिद्धिप्रदं लोके सर्वरोगनिवर्हणम् ॥ महोत्पातप्रशमनं ग्रहशान्तिकरं परम् । सर्वदेवमयं प्राज्यं सर्वशत्रुभयापहम् ॥ सर्वदुःखौघशमनं सर्वशोकविनाशनम् । पठेद्वा पाठयेन्नाम्नां सहस्रं शक्तिसन्निधौ ॥ दूरादेव पलायन्ते विपदः शत्रुभीतयः । राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः ॥ पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः । श्रवणात्पातकं नश्येच्छ्रावयेद्यः सुभाग्यवान् ॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । सहस्रनामपाठे तु फलमाप्नोति मानवः ॥ गङ्गास्नानसहस्राणि चान्द्रायणयुतानि च । तप्तकृच्छ्रस्य लक्षाणि पराकस्यायुतानि च ॥ सहस्रनामपाठस्य कलां नार्घन्ति षोडशीम् । सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् ॥ मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि । वर्षमेकं शतावर्तं महाचीनक्रमाकुलः ॥ शक्तिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि । श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् ॥ परदारार्चनरतो भगबिम्बं स्मरन्सुधीः । पठेन्नामसहस्रं तु वसुकामो लभेद्धनम् ॥ रात्रौ वारत्रयं देवि पठेन्नामसहस्रकम् । मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः ॥ स्वप्ने सिंहासनां राज्ञीं वरदां सोपि पश्यति ।

क्षीराचरणसन्तृप्तो वीरपानरसालसः ॥ यः पठेत्परया भक्त्या राज्ञीनामसहस्रकम् । स सद्यो मुच्यते घोरान्महापातकजाड्ड्यात् ॥ यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः । शुक्रोत्तरेण काले तु तस्य हस्ते च सिद्धयः ॥ यः पठेन्निशि चक्राग्रः परस्त्रीध्यानतत्परः । सर्वस्वं वरमानन्दी स लभेत्संयुगे जयम् ॥ इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे । भूर्जत्वचि लिखेद्रात्रौ चक्रार्चनसमागमे ॥ अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके । धारयेत्कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥ यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम् । रणे राजकुले द्यूते चौररोगाद्युपद्रवे ॥ समाप्नोति जयं सद्यः साधको धीरनायकः । श्रीचक्रं पूजयेद्यस्तु धारयेद्यो हि मस्तके ॥ पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा । किं किं न लभते कामं देवानामपि दुर्लभम् ॥ सुरापात्रं ततः संविच्चर्वणं मीनमांसकम् । नवकन्यासमायोगो मुद्रावीणारवाः प्रिये ॥ तत्सङ्गो गुरुसान्निध्यं राज्ञीश्रीचक्रमग्रतः । यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः ॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् ॥ अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने । गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च ॥ नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः ॥ देयं शिष्याय शान्ताय भक्तायाऽद्वैतवादिने ॥ दीक्षिताय कुलीनाय राज्ञीभक्तिपराय च । दत्त्वा भोगापवर्गत्वं लभेत्साधकसत्तमः ॥ इति नामसहस्रं तु राज्ञ्याः शिवमुखोद्गतम् । अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥

इति श्रीरुद्रयामले तन्त्रे श्रीमहाराज्ञीनामसहस्रं समाप्तम् ॥

अथ ज्वालामुखीसहस्रनामस्तोत्रम् ॥

श्रीदेव्युवाच ॥ ॐभगवन्सर्वधर्मज्ञ भक्तानामभयप्रद । पुरा मे यत्त्वया दत्तो वरः कैलाससानुतः ॥ कृपया परया नाथ तं मे दातुं क्षमो भव ॥ श्रीभैरव उवाच ॥ सत्यमेतन्मया प्रोक्तं वरं वरय पार्वति । तं प्रयच्छामि संसिद्ध्यै मनसा यदभीप्सितम् ॥ श्रीदेव्युवाच ॥ ज्वालामुख्यास्त्वया देव सहस्राणि च तत्वतः । प्रोक्तानि ब्रूहि नामानि यदि मे त्वत्कृपा भवेत् ॥ श्रीभैरवः ॥ प्रवक्ष्यामि महादेवि ज्वालानामानि तत्त्वतः । सहस्राणि कलौ नृणां वरदानि यथेप्सितम् ॥ अभक्ताय न दातव्यं सहस्राणां स्तवोत्तमम् । या सा ज्वालामुखी देवी त्रैलोक्यजननी स्मृता । तस्या नामानि वक्ष्यामि दुर्लभानि जगत्त्रये । विना नित्यबलिं स्तोत्रं न रक्ष्यं साधकोत्तमैः । दुर्भिक्षे शत्रुभीतौ च मारणे स्त-म्भने पठेत् । सहस्राख्यं स्तवं देव्याः सद्यः सिद्धिर्भविष्यति । विना गन्धाक्षतैः पुष्पैर्धूपैर्दीपैर्विना बलिम् । न रक्ष्यं साधके-नैव ज्वालानामसहस्रकम् । देवि सत्यं मया प्रोक्तं सर्वसिद्धिर्भ-विष्यति ॥ ॐ अस्य श्रीज्वालामुखीसहस्रनामस्तोत्रस्य, भैरवऋषिः, त्रिष्टुप्छन्दः, अद्वैतरूपिणी ज्वालामुखी देवता, ह्रींबीजं, श्रींशक्तिः, ॐकीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीज्वालामुखी-प्रसादसिद्ध्यर्थं पाठे होमे वा विनियोगः ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति न्यासः ॥ ध्यानं ॥ ॐ उद्यच्चन्द्रमरीचिसन्निभमुखीमेकाद-शाराब्जगां पाशाम्भोजवराभयां करतलैः संबिभ्रतीमादरात् । अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥ ॐज्वालामुख्यै

विद्महे, जगद्भक्षिण्यै धीमहि, तन्नो ज्वाला प्रचोदयात् ॥ ३ ॥ मूलं ॥ ॐ ह्रींश्रींज्वालामुखि मम सर्वशत्रून् भक्षय भक्षय ह्रींफट् स्वाहा १०८ ॥ श्रीभैरवः ॥ ॐह्रींज्वालामुखी जैत्री श्रीज्योत्स्ना जयदा जया । औदुम्बरा महानीला शुक्लिप्ता शची श्रुतिः । स्मयदा स्मयहर्त्री च स्मरशत्रुप्रियङ्करी । मानदा मोहिनी मत्ता माया बाला बलन्धरा । भगरूपा भगावासा भीरुण्डा भयघातिनी । भीतिर्भयानकास्या च भ्रूः सुभ्रूः सुखिनी सती । शूलिनी शूलहस्ता च शूलिवामाङ्गवासिनी । शशाङ्कजननी शीता शीतला शारिका शिवा । शुचिका मधुमन्मान्या त्रिवर्गफलदायिनी । त्रेता त्रिलोचना दुर्गा दुर्गमा दुर्गतिर्गतिः । पूता प्लुतिर्विसर्गा च सृष्टिकर्त्री सुखावहा । सुखदा सर्वमध्यस्था लोकमाता महेश्वरी । लोकेष्टा वरदा स्तुत्या स्तुतिर्द्युतिर्गतिर्नुतिः । नयदा नयनेत्रा च नवग्रहनिषेविता । अम्बा वरूथिनी वीरजननी वीरसुन्दरी । वीरसर्वाङ्गणी वार्ता वराभयकरा वधूः । वानीरतलगा वाम्या वामाचारफलप्रदा । वीरा चौर्यकरी शान्ता शार्दूलत्वक्क शर्वरी । शलभी शास्त्रमर्यादा शिवदा शम्बरान्तका । शम्बरारिप्रिया शम्भुकान्ता शशिनिभानना । शस्त्रायुधधरा धीरा ज्योतिर्दीप्तिर्जगत्प्रिया । जगती जित्वरी जारी मार्जारी पशुपालिनी । मेरुमध्यगता मैत्री मुसलायुधधारिणी । मान्या मन्त्रेष्टदा माध्वी माध्वीरसविघूर्णिता । मोदकाहारमत्ता च मत्तमातङ्गगामिनी । महेश्वरप्रियोन्मत्ता दार्वी दैत्यविमर्दिनी । देवेष्टा साधकेष्टा च साध्वी सर्वत्रगा समा । सन्तानकतरुच्छाया

सन्तुष्टाऽध्वश्रमापहा । शारदा शरदब्जाक्षी शरच्चन्द्रनिभानना । नम्राङ्गी कर्कशाङ्गी च वज्राङ्गी वज्रधारिणी । वज्रेष्टा वज्रकङ्काली वानरी वायुवेगिनी । वराकी कुलकी काम्या कुलेष्टा कुलकामिनी । कुन्ता कामेश्वरी क्रूरा कुल्या कामान्तकारिणी । कुन्ती कुन्तधरा कुब्जा काष्टदा बगलामुखी । मृडानी मधुरा मूका प्रमत्ता वैन्धवीश्वरी । कुमारी कुष्टहा काम्या कूवरी नडकूवरी । नगेश्वरी नगावासा नगपुत्री नगारिहा । नागकन्या कुहू कुण्ठी करुणा कृपयान्विता । ककारवर्णरूपाढ्या ह्रीर्लज्जा श्रीः शुभाऽशुभा । खेचरी खगपुत्री च खगनेत्रा खगेश्वरी । खाता खनित्री खस्था च जप्या जप्ता जरात्मिका । जगती जन्मदा जम्भी जम्बुवृक्षतलस्थिता । जाम्बूनदप्रिया सत्या सात्त्विकी सत्वसंस्थिता । सर्वमाता समालोका लोकाख्यातिर्लयात्मिका । लूता लतारतिर्लाजा वाजिगा वारुणीप्रिया । कुटिला कुत्सिता ब्राह्मी ब्रह्माणी ब्रह्मदायिनी । व्रतेष्टा वाजिनी वस्तिर्वामनेत्रा वशङ्करी । शाङ्करी शङ्करेष्टा च शशाङ्ककृतशेखरा । कुम्भेश्वरी कुरुघ्नी च पाण्डवेष्टा परात्परा । महिषासुरसंहर्त्री माननीया मनुप्रिया । दक्षिणा दक्षजा दक्षा द्राक्षा दूती धराद्युतिः । धर्मदा धर्मराजेष्टा धर्मस्था धर्मपालिनी । धनदा धनिका धर्म्या पताका पार्वती प्रजा । प्रजावती पुरी प्रज्ञा पूः पुत्री पत्रिवाहिनी । पत्रिहस्ता च मातङ्गी पुत्रिका च पतिव्रता । पुष्टिः पुक्षा श्मशानस्था देवी धनदसेविता । दयावती दयापूरा गयानिकटवासिनी । नर्मदा शर्मदा नन्दा नाकिनी नाकिसेविता । नासा संका-

न्तिरीड्या च भैरवी च्छिन्नमस्तिका । श्यामा श्यामाम्बरा पीता पीतवस्त्रा कलावती । कुन्तकी कौतुकाचारा कुलधर्मप्रकाशिनी । शाम्भवी गारुडीविद्या गरुडासनसंस्थिता । विनता वैनतेयेष्टा वैष्णवी विष्णुपूजिता । वार्ताका वालुकावेत्री वेत्रहस्ता वराङ्गना । विवेकलोचना लुप्ता नौर्नारायणपूजिता । नारायणी च सुमुखी दुर्जया दुःखहारिणी । दुर्भाग्यहा दुराचारा दुष्टहर्त्री च द्वेषिणी । वाङ्मयी भारती भाषा मषी लेखकपूजिता । लेखपत्री च लोलाक्षी लास्या हास्यप्रियङ्करी । प्रमदा प्रणयज्ञा च प्रमाणप्रत्ययाङ्किता । वाराही कुब्जिकाकारा कारावन्धनमोक्षदा । उग्रा चोग्रतरोग्रेष्टा नृमान्या नारसिंहिका । नरनारायणस्तुत्या नरवाहनपूजिता । नृमुण्डा नूपुराढ्या च नृमाता त्रिपुरीश्वरी । दिव्यायुधोग्रतारा च त्र्यक्षा त्रिपुरमालिनी । त्रिनेत्रा कोटराक्षी च षट्चक्रस्था क्रमेश्वरी । क्रिमिका क्रिमियोनिश्च कला चन्द्रकला चमूः । चर्माम्बरा च चार्वङ्गी चञ्चलाक्षी च भद्रदा । भद्रकाली सुभद्रा च भद्राङ्गी प्रेतवाहिनी । सुषमा स्त्रीप्रिया कान्ता कौलिनी कुटिलालका । कुशब्दा कुगतिर्मध्या मध्यमा ज्या च काश्यपी । दक्षिणा कालिका काली कालभैरवपूजिता । क्लींकारी कुमतिर्वाणी वाणासुरनिसूदिनी । निर्मदा निर्ममेष्टा च नरयोनिर्निराश्रया । निर्विकारा निरीक्ष्या च निलया नृपपुत्रिणी । नृपसेव्या विरिञ्चेष्टा विशिष्टा विश्वमातृका । मातृकार्णविलिप्ताङ्गी मधुस्नाता मधुस्रवा । शुक्रेष्टा शुक्रसन्तुष्टा शुक्रस्नाता कृशोदरी । वृषा वृष्टिरनावृष्टिर्लभ्या लोभविवर्जिता । लुब्धिश्च

ललना लक्ष्या लक्ष्मी रामा रमा स्तुतिः । रेवा रम्भोर्वशी वश्या वासुकिप्रियकारिणी । शेषा शेषरता श्रेष्ठा शेषशायिनमस्कृता । शिष्या शर्वप्रिया शस्ता प्रशस्ता शम्भुसेविता । आशुशुक्षणिनेत्रा च क्षणदा क्षणसेविता । क्षुरिका कर्णिकासंस्था साचाराऽचाररूपिणी । चरित्री च धरित्रीशी देवदैत्येन्द्रपूजिता । गुणिनी गुणरूपा च त्रिगुणा निर्गुणा घृणा । घोषा गजाननेष्टा च गजाकारा गजप्रिया । गीता गीतप्रिया तथ्या पथ्या त्रिपुरसुन्दरी । पीनस्तनी च रमणी रमणेष्टा च मैथिली । पद्मा पद्मधरा वत्सा धेनुर्मेरुधरा मघा । मालती मधुरालापा मातृज्ञा मासिनी तथा । वैश्वानरप्रिया वेद्या चिकित्सा वैद्यपूजिता । वेदिका वारपुत्री च वयस्था वाग्भवी प्रसूः । क्रीता पद्मासना सिद्धा सिद्धलक्ष्मीः सरस्वती । सत्त्वश्रेष्ठा सत्त्वसंस्था सामान्या सामवायिका । साधकेष्टा च सत्पत्नी सत्पुत्री सत्कुलाश्रया । समदा प्रमदा प्रान्ता परलोकगतिप्रदा । घोररूपा घोररावा मुक्तकेशी च मुक्तिदा । मोक्षदा बलदा मुक्तिर्भुक्तिर्बलिप्रिया बला । तिलप्रसूननासा च प्रसूना कुलशीर्षिणी । परद्रोहकरी पन्थाः पारावारसुता भगा । भगप्रिया भर्गरता होला हैमवतीश्वरी । हेरुकेष्टा वटुस्था च वटुमाता वटेश्वरी । नटिनी त्रोटिनी त्राता स्वसा सारवती सभा । सौभाग्यभाग्यदा भाग्या भोगदा भूः प्रभावती । चन्द्रिका कालहर्त्री च ज्योत्स्नोल्काऽशनिरह्निका । ऐहिक्यामुष्मिकी चोष्मा ग्रीष्मार्कद्युतिरूपिणी । ग्रीवा ग्रीष्मा नागकन्या कैलासाचलवासिनी । मल्ली मार्तण्डरूपा च मानहर्त्री

मनोरमा । मानिनी मानकर्त्री च मानसी तापसीश्वरी। पयःस्था तु परंब्रह्मस्तुता स्तोत्रप्रिया तनुः । तन्वी तनुतरा सूक्ष्मा स्थूला शूरप्रियाऽधमा । उत्तमा मणिभूषाढ्या मणिमण्डपसंस्थिता । भार्या तीक्ष्णा त्रपा चिन्ता चण्डिका चर्चिका चला । चण्डी चुल्ली चमत्कारकर्त्री हरिहरेश्वरी । हरिसैन्या कपिश्रेष्ठा चर्चिता चारुरूपिणी । चण्डेश्वरी चण्डरूपा मुण्डहस्ता मनोगतिः । पूता प्रोता पवित्रा च मज्जा मेध्या सुगन्धिनी । सुगन्धा पुष्पिणी पुष्पा प्रेरिता पवनेश्वरी । प्रेता क्रोधाकुला न्यस्ता न्यक्काराम्बरवाहिनी । स्रोतस्वती मधुमती वेदमाता सुरा सुधा । मत्स्या मत्स्येन्द्रपीठस्था वीरपानमदातुरा। पृथिवी तैजसी तृप्तिर्मूलाधारा प्रभा पृथुः । नागपाशधराऽनन्ता पाशहस्तप्रबोधिनी । प्रसाधना कलिङ्गाख्या मदनाशा मदद्रवा । मधुवीरा मदान्धा च पावनी वेदना स्मृतिः । बोधिका बोधिनी पुष्टिः काशी वाराणसी गया । कौशिक्युज्जयिनी धारा काश्मीरी कुङ्कुमालया । भूमिः सिन्धुः प्रभासा च गङ्गा गौरी शुभाश्रया । नानाविद्यामयी वेत्रवती गोदावरीनदी । गदहर्त्री गजारूढा चेन्द्राणी कुरुकौलिनी । कुलाचारा कुरूपा च सुरूपा रूपवर्जिता । चन्द्रभागा च यमुना यामी यमक्षयङ्करी । काम्भोजी सरयूश्चित्रा वितस्तैरावती झषा । चषका मथिका तन्त्री वीणा वेणुप्रियंकरी । कुण्डलिनी निर्विकारा गायत्री नरकान्तका । कृष्णा सरस्वती तापी पयोष्णी शतरुद्रिका । कावेरी शतपत्राभा शतबाहुः शतह्रदा । रेवती रोहिणी क्षिप्या क्षीणा क्षोणी क्षमा क्षया । क्षान्तिर्भ्रान्तिर्गुरुर्गुर्वी ग-

रिष्ठा गोकुलालया । नादिनी कूंपिणी कुष्ठा सत्कुटी भूमिका भ्रमा । विभ्राजमाना तीर्था च तीर्थाऽतीर्थफलप्रदा । तरुणी तापसी पार्शी विपाशा पाशधारिणी । पशूपहारसन्तुष्टा कुक्कुटी हंसवाहना । मदना विपुला काण्डी वेदकाण्डी विचित्रिणी । स्वप्नावती सरित्सीताधारिणी मत्सरी चमत् । शतद्रूर्भारती कद्रूरनन्तानन्तशायिनी । वेदना वासवी वेश्या पूतना पुष्पहासिनी । त्रिशक्तिः शक्तिरूपा च क्षुरमाता क्षुरी क्षुधा । मन्दा मन्दाकिनी मुद्रा भूताभूतपतिव्रता । भूतेष्टा पञ्चभूतघ्नी स्वक्षा कोमलहासिनी । वासिनी कुहिका लम्बा लम्बकेशी सुकेशिनी । ऊर्ध्वकेशी विशालाक्षी घोरा पुण्यपतिव्रता । पांसुला पात्रहस्ता च खर्परी खर्परायुधा । केकरी काकिनी कुम्भी सुफला केकराकृतिः । विफला विजया श्रीदा श्रीदसेव्या शुभंकरी । शैत्या शीतालया शीधुपात्रहस्ता कृपावती । कारुण्यविश्वसारा च करुणा करुणाकुला । प्रज्ञाऽज्ञाना च षड्वर्गाषडास्या षण्मुखप्रिया । क्रौञ्ची क्रौञ्चाद्रिदलिनी दान्ता दारिद्र्यहारिणी । सुशीलभास्वरा साध्या साधनीया च सामगा । सप्तस्वरा सप्तिवाहा सप्तसप्तिविलोचना । स्थितिः क्षेमङ्करी स्वाहा वाचाली विधिभास्वरा । कालकण्ठी घोषधरा सुग्रीवा स्कन्दसंरुचिः । शुचिस्मिता समुद्रेष्टा शशिनी वशिनी सुदृक् । सर्वज्ञा सर्वदा शारी सुनासा सुरकन्यका । मीना मीनासुता शृङ्गी शृङ्गिनी हाटकेश्वरी । होटिका हारिणी लिङ्गा भगलिङ्गस्वरूपिणी । भगमाता च लिङ्गाख्या लिङ्गप्रीता कलिङ्गजा । कुमारी युवतिः प्रौढा नवोढा प्रौढरूपिणी । रम्या रजोवती

रज्जू राजोली राजसी घटी। कैवर्ती राक्षसी रात्री रात्रिञ्चर-क्षयङ्करी। महोग्रा मुदिता भिल्ली भल्लहस्ता भयङ्करी। नीलाभा द्वारिका द्वाःस्था दारिकामध्यदेशगा। चित्रलेखा वसुमती सुन्दराङ्गी वसुन्धरा। देवता पर्वतस्था च स्वयम्भूः परमाकृतिः। परमेशमुण्डमाला नागयज्ञोपवीतिनी। श्मशानकालिका श्मश्रुः प्रलयात्मप्रलोपिणी। प्रस्थस्था प्रस्थिनी प्रस्था धूम्रार्चिर्धूम्रधूमिनी। धूम्राङ्गी धूम्रकेशा च कपिला कालनाशिनी। कङ्काली कालरूपा च कालमाता मलिम्लुची। शर्वाणी रुद्रपत्नी च रूक्षा रुद्रस्वरूपिणी। सन्ध्या त्रिसन्ध्या संपूज्या सर्वैश्वर्यप्रदायिनी। कुलजा सत्यलोकेशा सत्यवाक् सत्यवादिनी। सप्तस्वरा सत्यमयी हरिद्वारा हरिन्मयी। हरिद्रत्नमयी राशिर्ग्रहतारा तिथिस्तमी। तुम्बुरुस्त्रुटिका त्रोटिर्भुवनेशी भयापहा। राज्ञी राज्यप्रदा योग्या योगिनी भुवनेश्वरी। तुरीया च तमस्पारा ब्रीडा भंगी भयानका। कालरात्रिर्महारात्रिर्महाविद्या शिवालया। शिवसञ्ज्ञा शिवस्था च समाधिरग्निवाहना। अग्नीश्वरी सदाव्याप्तिर्बलाका बालरूपिणी। वटुकेशी वामरूपा सदसत्पुरभैरवी। विघ्नहा खलहा गाथा कथा कन्था शुभाम्बरा। ऋतुजा ऋतुहा क्रान्ता माधवेशाऽमरावती। अरुणाक्षी विशालाक्षी पुण्यशीला विलासिनी। स्वमाता स्कन्दमाता च कृत्तिका भरणी बलिः। जिनेश्वरी सुकुशला गोपी गोपतिपूजिता। गुप्ता गोप्यतरा ख्याता प्रकटा गोपितात्मिका। कुलाम्नायवती कीला पूर्णा स्वर्णाङ्गदोत्सुका। उत्कण्ठा कालकण्ठा च रक्तपा पानपाऽमला। सम्पूर्णचन्द्रवदना यशोदा

च यशस्विनी । आनन्दा सुन्दरी सर्वानन्दा नन्दात्मजाऽऽलया । विद्युत् खद्योतरूपा च सादरा जविका जनिः । मन्त्रदा मानदा मान्या सर्वपूज्या सुरेश्वरी । जनिकर्त्री जगद्रूपा जगद्वन्द्या प्रियङ्करी । मुग्धास्या मुग्धनेत्रा च लोकेशी च मनोरमा । वरदा शौर्यदा मुग्धा प्रेतस्था वह्निलोचना । अग्निमुखी महादीप्ती रौद्रा संहारकारिणी । बृहन्नेत्रा कृशाङ्गी च घोरा घोरतरा, शिवा । देवेन्द्रसेविता नित्या भाग्यदा सर्वमङ्गला । सौख्यदा शुभकर्त्री च भक्तानांहितकारिणी । जननी जनिहर्त्री च जम्भारिवरदा जनुः । जीर्णा जीमूतलक्ष्या च जयिनी जयवर्धिनी । जलस्था च जयन्ती च जम्भारिप्रियकारिणी । सहस्रनामसम्पूर्णा देवी ज्वालामुखीश्वरी । महादेवी महेशानी महात्रिपुरसुन्दरी ॥ इति नामस्तोत्रम् ॥ अथ नामावली ॥

ॐ ॐह्रींज्वालामुख्यैस्वाहा, जैत्र्यै, श्रींज्योत्स्नायै, जयदायै, जयायै, औदुम्बरायै, महानीलायै, शुक्रलिप्तायै, शच्यै, श्रुत्यै, स्मयदायै, स्मयहर्त्र्यै, स्मरशत्रुप्रियङ्कर्यै, मानदायै, मोहिन्यै, मत्तायै, मायायै, बालायै, बलन्धरायै, भगरूपायै, भगावासायै, भीरुण्डायै, भयघातिन्यै, भीत्यै, भयानकास्यायै, भ्रुवे, सुभ्रुवे, सुखिन्यै, सत्यै, शूलिन्यै, शूलहस्तायै, शूलिवामाङ्गवासिन्यै, शशाङ्कजनन्यै, शीतायै, शीतलायै, शारिकायै, शिवायै, स्रुचिकायै, मधुमन्मान्यायै, त्रिवर्गफलदायिन्यै, त्रेतायै, त्रिलोचनायै, दुर्गायै, दुर्गमायै, दुर्गतये, गतये, पूतायै, पुत्यै, विसर्गायै, सृष्टिकर्त्र्यै, सुखावहायै, सुखदायै, सर्वमध्यस्थायै, लोकमात्रे, महेश्वर्यै, लोकेष्टायै, वरदायै, स्तु-

त्यायै, स्तुतये, द्रुतगतये, नुतये, नयदायै, नयनेत्रायै, नवग्रहनिषेवितायै, अम्बायै, वरूथिन्यै, वीरजनन्यै, वीरसुन्दर्यै, वीरस्वै, वारुण्यै, वार्तायै, वराभयकरायै, वध्वै, वानीरतलगायै, वाम्यायै, वामाचारफलप्रदायै, वीरायै, चौर्यकर्यै, शान्तायै, शार्दूलत्वचे, शर्वर्यै, शलभ्यै, शास्त्रमर्यादायै, शिवदायै, शम्बरान्तकायै, शम्बरारिप्रियायै, शम्भुकान्तायै, शशिनिभाननायै, शस्त्रायुधधरायै, धीरायै, ज्योतिषे, दीप्तये, जगत्प्रियायै, जगत्यै, जित्वर्यै, जायै, मार्जार्यै, पशुपालिन्यै, मेरुमध्यगतायै, तेजोसि मैत्र्यै स्वाहा ॥ ध्यानं ॥ ॐ मुसलायुधधारिण्यैस्वाहा, ॐ मान्यायै, मन्त्रेष्टदायै, माध्व्यै, माध्वीरसविघूर्णितायै, मोदकाहारमत्तायै, मत्तमातङ्गगामिन्यै, महेश्वरप्रियायै, उन्मत्तायै, दान्व्यै, दैत्यविमर्दिन्यै, देवेष्टायै, साधकेष्टायै, साध्व्यै, सर्वत्रगायै, समायै, सन्तानकतरुच्छायायै, सन्तुष्टायै, अध्वश्रमापहायै, शारदायै, शरदब्जाक्ष्यै, शरच्चन्द्रनिभाननायै, नम्राङ्ग्यै, कर्कशाङ्ग्यै, वक्राङ्ग्यै, वज्रधारिण्यै, वज्रेष्टायै, वज्रकङ्काल्यै, वानर्यै, वायुवेगिन्यै, वराक्यै, कुलक्यै, काम्यायै, कुलेष्टायै, कुलकामिन्यै, कुन्तायै, कामेश्वर्यै, क्रूरायै, कुल्यायै, कामान्तकारिण्यै, कुन्त्यै, कुन्तधरायै, कुब्जायै, काष्टदायै, बगलामुख्यै, मृडान्यै, मधुरायै, मूकायै, प्रमत्तायै, बैन्दुवीश्वर्यै, कुमार्यै, कुष्टहायै, काम्यायै, कूवर्यै, नडकूवर्यै, नगेश्वर्यै, नागावासायै, नगपुत्र्यै, नगारिघ्ने, नागकन्यायै, कुह्वै, कुण्ठ्यै, करुणायै, कृपयान्वितायै, ककारवर्णरूपाढ्यायै, ह्रियै, लज्जायै, श्रियै, शुभायै, अशुभायै, खेचर्यै, खगपुत्र्यै, खगनेत्रायै, खगेश्वर्यै, खातायै,

खनित्र्यै, खस्थायै, जप्यायै, जप्तायै, जर्रांत्मिकायै, जगतो-जन्मदायै, जम्भ्यै, जम्बुवृक्षतलस्थितायै, जाम्बूनदप्रियायै, सत्यायै, सात्त्विक्यै, सत्त्वसंस्थितायै, सर्वमात्रे, समालोकायै, लोकाख्यांत्यै, लयात्मिकायै, लूतायै, लतारतये, लाजाभ्यः, वाजिगायै वारुणीप्रियायै, कुटिलायै, कुत्सितायै, ब्राह्म्यै, तेजोसि ॐ ब्रह्माण्यैस्वाहाँ ॥ ध्यानं ॥ ॐ ब्रह्मदायिन्यै स्वाहा, व्रतेष्टायै, वाजिन्यै, वस्त्यै, वामनेत्रायै, वशङ्क्यै, शाङ्क्यै, शङ्करेष्टायै, शशाङ्ककृतशेखरायै, कुम्भेश्वर्यै, कुरुघ्न्यै, पाण्डवेष्टायै, परात्परायै, महिषासुरसंहर्त्र्यै, माननीयायै, मनुप्रियायै, दक्षिणायै, दक्षजायै, दक्षायै, द्राक्षायै, दूत्यै, धराद्युतये, धर्मदायै, धर्मराजेष्टायै, धर्मस्थायै, धर्मपालिन्यै, धनदायै, धनिकायै, धर्म्यायै, पताकायै, पार्वत्यै, प्रजायै, प्रजावत्यै, पुर्यै, प्रज्ञायै, पुरे, पुत्र्यै, पत्रिवाहिन्यै, पत्रिहस्तायै, मातंग्यै, पुत्रिकायै, पतिव्रतायै, पुष्ट्यै, पुक्षायै, श्मशानस्थायै, देव्यै, धनदसेवितायै, दयावत्यै, दयापूरायै, गयानिकटवासिन्यै, नर्मदायै, शर्मदायै,नन्दायै, नाकिन्यै, नाकिसेवितायै, नासायै, सङ्क्रान्त्यै, ईड्यायै, भैरव्यै, च्छिन्नमस्तकायै, श्यामायै, श्यामाम्बरायै, पीतायै, पीतवस्त्रायै, कलावत्यै, कुन्तक्यै, कौतुकाचारायै, कुलधर्मप्रकाशिन्यै, शाम्भव्यै, गारुडीविद्यायै, गरुडासनसंस्थितायै, विनतायै, वैनतेयेष्टायै, वैष्णव्यै, विष्णुपूजितायै, वार्तोकायै, वालुकायै, वेत्र्यै, वेत्रहस्तायै, वराङ्गनायै, विवेकलोचनायै, लुप्तायै, नावे, नारायणपूजितायै, नारायण्यै, सुमुख्यै, दुर्जयायै, दुःखहारिण्यै, दुर्भाग्यहायै, दुराचारायै, दुष्टहर्त्र्यै, द्वेषिण्यै, वा-

क्ष्म्यै, भारत्यै, भाषायै, मष्यै, लेखकपूजितायै, लेखपत्र्यै, लोलाक्ष्यै, तेजोऽसि ॥ ॐ लास्यायै स्वाहाँ ॥ ध्यानम् ॥ ॐहास्यायै स्वाहा, प्रियङ्कर्यै, प्रमदायै, प्रणयज्ञायै, प्रमाणप्रत्ययाङ्कितायै, वाराह्यै, कुब्जिकाकारायै, काराबन्धनमोक्षदायै, उग्रायै, उग्रतरायै, उग्रेष्टायै, नृमान्यायै, नारसिंहिकायै, नरनारायणस्तुत्यायै, नरवाहनपूजितायै, नृमुण्डायै, नूपुराढ्यायै, नृमात्रे, त्रिपुरीश्वर्यै, दिव्यायुधायै, उग्रतारायै, त्र्यक्षायै, त्रिपुरमालिन्यै, त्रिनेत्रायै, कोटराक्ष्यै, षट्चक्रस्थायै, क्रमेश्वर्यै, क्रिमिकायै, क्रिमियोनये, कलायै, चन्द्रकलायै, चम्व्यै, चर्माम्बरायै, चार्वङ्ग्यै, चञ्चलाक्ष्यै, भद्रदायै, भद्रकाल्यै, सुभद्रायै, भद्राङ्ग्यै, प्रेतवाहिन्यै, सुषमायै, स्त्रीप्रियायै, कान्तायै, कौलिन्यै, कुटिलालकायै, कुशब्दायै, कुगतये, मेध्यायै, मध्यमायै, ज्यैायै, काश्यप्यै, दक्षिणाकालिकायै, काल्यै, कालभैरवपूजितायै, क्लींकार्यै, कुमत्यै, वाण्यै, बाणासुरनिसूदिन्यै, निर्मदायै, निर्ममेष्टायै, नरयोनये, निराश्रयायै, निर्विकारायै, निरीक्ष्यायै, निलयायै, नृपपुत्रिण्यै, नृपसेव्यायै, विरिञ्चेष्टायै, विशिष्टायै, विश्वमातृकायै, मातृकार्णविलिप्ताङ्ग्यै, मधुस्नातायै, मधुस्रुवायै, शुक्रेष्टायै, शुक्रसन्तुष्टायै, शुक्रस्नातायै, कृशोदर्यै, वृषायै, वृष्ट्यै, अनावृष्ट्यै, लुभ्यायै, लोभविवर्जितायै, लुब्ध्यै, ललनायै, लक्ष्यायै, लक्ष्म्यै, रामायै, रमायै, नुतये, रेवायै, रम्भायै, उर्वश्यै, वश्यायै, वासुकिप्रियकारिण्यै, शेषायै, शेषरतायै, श्रेष्ठायै, शेषशायिनमस्कृतायै, शिष्यायै, तेजोऽसि ॐशर्वप्रियायै स्वाहा, । ध्यानम् ॥ ॐश-स्तायैस्वाहा, प्रशस्तायै, शम्भुसेवितायै, आशुशुक्षणिनेत्रायै, क्ष-

णदायै, क्षणसेवितायै, क्षुरिकायै, कर्णिकासंस्थायै, साचारायै, आचाररूपिण्यै, चरित्र्यै, धरित्रीश्यै, देवदैत्येन्द्रपूजितायै, गुणिन्यै, गुणरूपायै, त्रिगुणायै, निर्गुणायै, घृणायै, घोषायै, गजाननेष्टायै, गजाकारायै, गजप्रियायै, गीतायै, गीतप्रियायै, तथ्यायै, पथ्यायै, त्रिपुरसुन्दर्यै, पीनस्तन्यै, रमण्यै, रमणेष्टायै, मैथिल्यै, पद्मायै, पद्मधरायै, वत्सायै, धेन्वै, मेरुधरायै, मघायै, मालत्यै, मधुरालापायै, मातृंजायै, मासिन्यै, वैश्वानरप्रियायै, वैद्यायै, चिकित्सायै, वैद्यपूजितायै, वेदिकायै, वारपुत्र्यै, वयस्यायै, वाग्भव्यै, प्रस्वै, क्रीतायै, पद्मासनायै, सिद्धायै, सिद्धलक्ष्म्यै, सरस्वत्यै, सत्वश्रेष्टायै, सत्त्वसंस्थायै, सामान्यायै, सामवायिकायै, साधकेष्टायै, सत्पत्न्यै, सत्पुत्र्यै, सत्कुलाश्रयायै, समदायै, प्रमदायै, प्रान्तायै, परलोकगतिप्रदायै, घोररूपायै, घोररावायै, मुक्तकेश्यै, मुक्तिदायै, मोक्षदायै, बलदायै, मुक्तये, भुक्तये, वलिप्रियायै, बलायै, तिलप्रसूननासायै, प्रसूनायै, कुलशीर्षिण्यै, परद्रोहकर्यै, पथे, पारावारसुतायै, भगायै, भगप्रियायै, भर्गरतायै, होलायै, हैमवत्यै, ईश्वर्यै, हेरुकेष्टायै, वटुस्थायै, वटुमात्रे, वटेश्वर्यै, नटिन्यै, त्रोटिन्यै, त्रात्रे, स्वस्त्रे, सारवत्यै, सभायै, तेजोसि ॐ सौभाग्यभाग्यदायै स्वाहा ॥ ध्यानम् ॥ ॐ भाग्यायै स्वाहा, भोगदायै, भुवे, प्रभावत्यै, चन्द्रिकायै, कालहर्त्र्यै, ज्योत्स्नायै, उल्कायै, अशनये, आह्निकायै, ऐहिक्यै, आमुष्मिक्यै, उष्मायै, ग्रीष्मार्कद्युतिरूपिण्यै, ग्रीवायै, ग्रीष्मायै, नागकन्यायै, कैलासाचलवासिन्यै, मह्यै, मार्तण्डरूपायै, मानहर्त्र्यै, मनोरमायै, मानिन्यै, मानकर्त्र्यै, मानस्यै, तापसी-

श्वर्यै, पयःस्थायै, परंब्रह्मस्तुतायै, स्तोत्रप्रियायै, तँन्वै, तन्व्यै, तनुतरायै, सूक्ष्मायै, स्थूलायै, शूरप्रियायै, अधमायै, उत्तमायै, मणिभूषाढ्यायै, मणिमण्डपसंस्थितायै, भार्षांयै, तीक्ष्णायै, त्रपायै, चिन्तायै, चण्डिकायै, चार्चिकायै, चलायै, चण्ड्यै, चुल्ल्यै, चमत्कारकर्त्र्यै, हरिहरेश्वर्यै, हरिसेन्यायै, कपिश्रेष्ठायै, चर्चितायै, चारुरूपिण्यै, चण्डेश्वर्यै, चण्डरूपायै, मुण्डहस्तायै, मनोगतये, पूतायै, प्रोतांयै, पवित्रायै, मज्ञायै, मेध्यायै, सुगन्धिन्यै, सुगन्धायै, पुष्पिण्यै, पुष्पायै, प्रेरितायै, पवनेश्वर्यै, प्रेतांयै, क्रोधाकुलायै, न्यस्तायै, न्यक्काराम्बरवाहिन्यै, स्रोतस्वत्यै, मधुमत्यै, वेदमात्रे, सुरायै, सुधायै, मत्स्यायै मत्स्येन्द्रंपीठस्थायै, वीरपानमदातुरायै, पृथिव्यै, तैजस्यै, वृक्ष्यै, मूलाधारायै, प्रभायै, पृथवे, नागपाशधरायै, अनन्तायै, पाशहस्तंप्रबोधिन्यै, प्रसाधनायै, कलिङ्गाख्यायै, मदनाशायै, मदद्रवायै, मधुवीरायै, मदान्धायै, पावन्यै, वेदनायै, स्मृत्यै तेजोसि ॐ बोधिकायैस्वाहां ॥ ध्यानं ॥ ओंबोधिन्यैस्वाहा, पुष्ट्यै, काश्यै, वाराणस्यै, गयायै, कौशिक्यै, उज्जयिन्यै, धारायै, काश्मीर्यै, कुंकुंमालयायै, भूम्यै, सिन्ध्वै, प्रभासायै, गङ्गायै, गौर्यै, शुभाश्रयायै, नानाविद्यामय्यै, वेत्रवत्यै, गोदावरीनद्यै, गदहंत्र्यै, गजारूढायै, इन्द्राण्यै, कुरुकौलिन्यै, कुलाचारायै, कुरूपायै, सुरूपायै, रूपवर्जितायै, चन्द्रभागायै, यमुनायै, यांम्यै, यमक्षयङ्कर्यै, काम्भोज्यै, सरय्वै, चित्रायै, वितस्तायै, ऐरावत्यै, झषायै, चषकायै, मथिकायै, तंत्र्यै, वीणायै, वेणुप्रियङ्कर्यै, कुण्डलिन्यै, निर्विकारायै, गायत्र्यै, नरकान्तकायै, कृष्णायै, सरस्वत्यै, ताप्यै,

पँयोष्ण्यै, शतरुद्रिकायै, कावेर्यै, शतपत्राभायै, शतबाहवे, शतह्रदायै, रेवत्यै, रोहिण्यै, क्षिप्यायै, क्षीणायै, क्षोण्यै, क्षमायै, क्षयायै, क्षान्त्यै, भ्रान्त्यै, गुरवे, गुर्व्यै, गरिष्ठायै, गोकुलालयायै, नादिन्यै, कृंषिण्यै, कृष्टायै, सत्कुट्यै, भूमिकायै, भ्रमायै, विभ्राजमानायै, तीर्थायै, तीर्थातीर्थफलप्रदायै, तरुण्यै, तापस्यै, पाशांयै, विपाशायै, पाशधारिण्यै, पशूपहारसन्तुष्टायै, कुकुट्यै, हंसवाहनायै, मदनायै, विपुलायै, काण्ड्यै, वेदकाण्ड्यै, विचित्रिंण्यै, स्वप्नावत्यै, सरिते, सीताधारिण्यै, मत्सर्यै, चमते, शतद्रै, भारत्यै कद्रै, अनन्तानन्तशायिन्यै तेजोसि ॥ ॐ वेदनायैस्वाँहा ॥ ध्यानं ॥ ॐ वासव्यैस्वाहा, वेश्यायै, पूतनायै, पुष्पहासिन्यै, त्रिशक्तये, शक्तिरूपायै, क्षुरमात्रे, क्षुर्यै, क्षुधायै, मन्दांयै, मन्दाकिन्यै, मुद्रायै, भूताभूतपतिव्रतायै, भूतेष्टायै, पञ्चभूतघ्न्यै, स्वक्षायै, कोमलहासिन्यै, चासिन्यै, कुहिकायै, लम्बांयै, लम्बकेश्यै, सुकेशिन्यै, ऊर्ध्वकेश्यै, विशालाक्ष्यै, घोरायै, पुण्यपतिव्रतायै, पांसुलायै, पात्रहस्तायै, खर्पर्यै खर्परायुंधायै, केकर्यै, काकिन्यै कुम्भ्यै, सफलायै, केकराकृतये, विफलायै विजयायै, श्रीदायै, श्रीदसेव्यायै, शुंभङ्कर्यै, शैत्यायै, शीतालयायै, शीधुपात्रहस्तायै, कृपावत्यै, कारुण्यविश्वसारायै, करुणायै, करुणाकुलायै, प्रज्ञायै, अज्ञानायै, षँड्वर्गायै, षडास्यायै, षण्मुखप्रियायै, क्रौञ्च्यै, क्रौञ्चाद्रिदलिन्यै, दान्तायै, दारिद्र्यहारिण्यै, सुशीलभास्वरायै, साध्यायै, साधनीयायै, सामगांयै, सप्तस्वरायै, सप्तिवाहायै, सप्तसप्तिविलोचनायै, स्थितये, क्षेमङ्कर्यै, स्वाहायै, वाचाल्यै,

विधिभास्वरायै, कालकण्ठ्यै, घोषघंरायै, सुग्रीवायै, स्कन्दसं-रुचये, शुचिस्मितायै, समुद्रेष्टायै, शशिन्यै, वशिन्यै, सुदृशे, सर्वज्ञायै, सर्वदायै, शांयै, सुनासायै, सुरकन्यकायै, मीनायै, मीनासुतायै, भृङ्ग्यै, भृङ्गिन्यै, हाटकेश्वर्यै, होटिकायै, हा-रिण्यै, लिङ्गांयै, भगलिङ्गस्वरूपिण्यै, भगमात्रे, लिङ्गाख्यायै, लिङ्गप्रीतायै, कलिङ्गजायै, कुमार्यै, युवत्यै, प्रोढायै, नवोढायै, तेजोसि ॐ प्रौढरूपिण्यैस्वाहा ॥ ८०० ध्यानम् ॥ ॐ रम्यायैस्वाहा, रजोवत्यै, रज्वे, राजोल्यै, राजस्यै, घट्यै, कैवर्त्यै, राक्षस्यै, रात्र्यै, रात्रिंश्वरक्षयङ्कर्यै, महोग्रायै, मुदितायै, भिल्ल्यै, भल्ल-हस्तायै, भयङ्कर्यै, नीलाभायै, द्वारिकायै, द्वाःस्थायै, द्वारिका-मध्यदेशगायै, चित्रलेखायै, वसुमत्यै, सुन्दराङ्ग्यै, वसुंधरायै, देवतायै, पर्वतस्थायै, स्वयम्भुवे, परमाकृतये, परमेशमुण्डमा-लायै, नागयज्ञोपवीतिन्यै, श्मशानकालिकायै, श्मश्रवे, प्रल-यात्मप्रलोपिन्यै, प्रस्थस्थायै, प्रस्थिन्यै, प्रस्थायै, धूम्रार्चिषे, धूम्रधूमिन्यै, धूम्राङ्ग्यै, धूम्रकेशायै, कपिलांयै, कालनाशिन्यै, कङ्काल्यै, कालरूपायै, कालमात्रे, मलिम्लुच्यै, शर्वाण्यै, रुद्र-पत्न्यै, रूक्षायै, रुद्रस्वरूपिण्यै, सँन्ध्यायै, त्रिसन्ध्यायै, संपूज्यायै, सर्वैश्वर्यप्रदायिन्यै, कुलजायै, सत्यलोकेशायै, सत्यवाचे, सत्य-वादिन्यै, सप्तस्वरायै, सत्यमय्यै, हरिद्रांरायै, हरिन्मय्यै, हरि-द्रत्नमय्यै, राश्यै, ग्रहतारायै, तिथ्यै, तम्यै, तुम्बुरवे, त्रुटिकायै, त्रोट्यै, भुँवनेश्यै, भयापहायै, राज्यै, राज्यप्रदायै, योग्यायै, योगिन्यै, भुवनेश्वर्यै, तुरीयायै, तमस्पारायै, व्रीडायै, भंर्ग्यै, भयानकायै, कालरात्र्यै, महारात्र्यै, महाविद्यायै, शिवा-

लयायै, शिवसङ्गायै, शिवस्थायै, समाध्यै, अग्निवाहनायै, अंग्नीश्वर्यै, सदाव्यास्यै, वलाकायै, बालरूपिण्यै, वटुकेश्यै, वामरूपायै, सते, असते, पुरभैरव्यै, विघ्नहायै, तेजोसि ॐ खलहायै स्वाहा ॥ ध्यानम् ॥ गाथायै, कथायै, कन्थायै, शुभाम्बरायै, ऋतुजायै, ऋतुहायै, क्रान्तायै, माधवेशायै, अमरावत्यै, अरुणाक्ष्यै, विशालाक्ष्यै, पुण्यशीलायै, विलासिन्यै, स्वमात्रे, स्कन्दमात्रे, कृत्तिकायै, भरण्यै, वलये, जिनेश्वर्यै, सुकुशलायै, गोप्यै, गोपतिपूजितायै, गुप्तायै, गोप्यतरायै, ख्यातायै, प्रकटायै, गोपितात्मिकायै, कुलाम्नायवत्यै, कीलायै, पूर्णायै, स्वर्णाङ्गदायै, उत्सुकायै, उत्कण्ठायै, कालकण्ठायै, रक्तपायै, पानपायै, अमलायै, सम्पूर्णचन्द्रवदनायै, यशोदायै, यशस्विन्यै, आनन्दायै, सुन्दर्यै, सर्वानन्दायै, नन्दात्मजायै, आलयायै, विद्युते, खद्योतरूपायै, सादरायै, जविकायै, जन्यै मन्त्रदायै, मानदायै, मान्यायै, सर्वपूज्यायै, सुरेश्वर्यै, जनिकर्त्र्यै, जगद्रूपायै, जगद्वन्द्यायै, प्रियङ्कर्यै, मुग्धास्यायै, मुग्धनेत्रायै, लोकेश्यै, मनोरमायै, वरदायै, शौर्यदायै, मुग्धायै, प्रेतस्थायै, वह्निलोचनायै, अग्निमुख्यै, महादीप्त्यै, रौद्रायै, संहारकारिण्यै, बृहन्नेत्रायै, कृशाङ्ग्यै, घोरायै, घोरतरायै, शिवायै, देवेन्द्रसेवितायै, नित्यायै, भाग्यदायै, सर्वमङ्गलायै, सौख्यदायै, शुभकर्त्र्यै, भक्तानांहितकारिण्यै, जनन्यै जनिहर्त्र्यै, जम्बारिवरदायै, जनवे, जीर्णायै, जीमूतलक्ष्यायै, जयिन्यै, जयवर्धिन्यै, जलस्थायै, जयन्त्यै, जम्बारिप्रियकारिण्यै, सहस्रनामसम्पूर्णायै ज्वालामुखीश्वरीदेव्यै, महादेव्यै, महेशान्यै, तेजोसि ॐ महात्रिपुरसुन्दर्यै स्वाहा ॥ इति

नाम्नां सहस्रं तु ज्वालामुख्याः शिवोदितम् । चतुर्वर्गप्रदं नित्यं
बीजत्रयप्रकाशितम् । मुक्त्यैकहेतुममलं भुक्तिमुक्तिप्रदं नृणाम् ।
स्तुत्यं च साधनीयं च सर्वस्वं सारमुत्तमम् । महामन्त्रमयं विद्या-
मयं विद्याप्रदं परम् । परब्रह्मस्वरूपं च साक्षादमृतरूपिणम् ।
अद्वैतरूपिणं नाम्नां सहस्रं भैरवोदितम् । यः पठेत्पाठयेद्वापि
शृणोति श्रावयेदपि । भक्त्या भक्तो महादेवि स भवेद्भैरवो-
पमः । शिवरात्र्यां च सङ्क्रान्तौ ग्रहणे जन्मवासरे । भैरवस्य
बलिं दत्त्वा मूलमन्त्रेण मान्त्रिकः । पठेत्सहस्रनामेदं ज्वाला-
मुख्याः सुदुर्लभम् । अनन्तफलदं गोप्यं त्रिसन्ध्यं यः पठे-
त्सुधीः । अणिमादिविभूतीनामीश्वरो मान्त्रिको भवेत् । अर्ध-
रात्रे समुत्थाय शून्ये गेहे पठेदिदम् । नाम्नां सहस्रकं देवि त्रि-
वारं साधकोत्तमः । कर्मणा मनसा वाचा ज्वालामुख्याः सुतो
भवेत् । मध्याह्ने प्रत्यहं गत्वा प्रेतभूमिं विधानवित् । नरमांस-
बलिं दत्त्वा पठेन्नामसहस्रकम् । दिव्यदेहधरो भूत्वा विचरे-
द्भुवनत्रयम् । शनिवारे कुजेऽष्टम्यां पठेन्नामसहस्रकम् । दत्त्वा
क्षीरबलिं तस्य करस्थाः सर्वसिद्धयः । विना नैवेद्यमात्रेण न
रक्ष्यं साधकोत्तमैः । कुजवारे सदा देवि दत्त्वा बलिविधिं नरः ।
पठेत्साधक एवाशु लभेद्दर्शनमुत्तमम् । शनिवारे सदा विद्यां
जप्त्वा दद्याद्बलिं प्रिये । कपोतस्य महेशानि पठेन्नामसहस्रकम् ।
तद्गृहे वर्धते लक्ष्मीर्गोकर्णमिव नित्यदा । शतावर्तं पठेद्रात्रौ
साधको दर्शनं लभेत् । वन्ध्या वा काकवन्ध्या वा कुङ्कुमेन
लिखेदिदम् । मस्तकेन च शुक्रेण भूर्जे नामसहस्रकम् । गले वा
वामबाहौ वा धारयेत्प्रत्यहं प्रिये । वन्ध्या च लभते पुत्रान्क-

शान्विद्याधरोपमान् । इदं बध्वा सव्यबाहौ गत्वा रणधरां प्रति । निर्जित्य शत्रुसङ्घांस्तान्प्रत्यायाति सुखी गृहम् । वारत्रयं पठेन्नित्यं शत्रुनाशाय पार्वति । वारद्वयं पठेल्लक्ष्म्यै मुक्त्यै च शतधा पठेत् । वश्यार्थी दशधा नित्यं मारणार्थे च विंशति । स्तम्भनार्थे पठेन्मन्त्री सप्तधा मान्त्रिकोत्तमः । भूम्यर्थे त्रिंशधा देवि पठेन्नामसहस्रकम् । प्रत्यहमेकवारं तु मृतो मोक्षमवाप्नुयात् । अप्रकाश्यमदातव्यमवक्तव्यमभक्तिषु । असक्तायाऽकुलीनाय कुपुत्राय दुरात्मने । गुरुभक्तिविहीनाय दीक्षाहीनाय पार्वति । दत्त्वा कुष्ठी भवेल्लोके परत्र नरकं व्रजेत् । श्रद्धायुक्ताय भक्ताय साधकाय महात्मने । साचाराय सुशीलाय दत्त्वा मोक्षमवाप्नुयात् । यो धारयति पुण्यात्मा सोपि पुण्यवतां वरः ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये ज्वालामुखीसहस्रनामस्तोत्रं समाप्तम् ॥

ॐ श्रीशारिकासहस्रनामस्तोत्रम् नामावली च ॥

श्रीभैरवी । या सा देवी पुरा ख्याता शारिकारूपधारिणी । जालन्धरराक्षसघ्नी प्रद्युम्नशिखरे स्थिता । तस्या नामसहस्रं मे मन्त्रगर्भं जयावहम् । कथयस्व महादेव यद्यस्ति मयि ते दया । श्रीभैरवः । या देवदेवी भद्राख्या त्रिकोटिदेवसंयुता । महासुरविनाशाय शारिकारूपधारिणी । कूटं सुमेरोः चञ्च्वग्रे समादायागताम्बिका । त्रयस्त्रिंशतिकोट्यश्च देवानां वै समागताः । तस्या नामसहस्रं ते मन्त्रगर्भं जयावहम् । कथयामि परां विद्यां सहस्राख्याभिधां शिवे । शिलायाः शारिकाख्यायाः परां

सर्वस्वरूपिणीम् । विना नित्यक्रियां देवि विना न्यासं विना-
र्चनम् । विना पुरस्क्रियां देवि होमार्चादि विना परम् । विना
श्मशानगमनं विना समयपूजनम् । यया लभेत्फलं सर्वं तां
विद्यां शृणु पार्वति । या देवी चेतना लोके शिलारूपास्ति
शारिका । सृजत्यवति सा विश्वं संहरिष्यति तामसी । रजो-
गुणेन सृजति सत्त्वेनावति संसृतिम् । तमसा संहरेत्सैव त्रि-
ब्रह्मरूपधारिणी । सैव संसारिणां देवी परमैश्वर्यदायिनी । परं
पदं प्रदास्यन्ती महाविद्यात्मिका शिला । तस्या नामसहस्रं ते
वर्णयामि सहस्रकम् । रहस्यं मम सर्वस्वं सकलाचारवल्लभम् ।
यो जपेत्परमां विद्यां पठेन्नामसहस्रकम् । धारयेत्कवचं दिव्यं
पठेत्स्तोत्रेश्वरं परम् । किं तस्य दुर्लभं लोके नाप्नुयाद्यद्यदीश्वरि ।
॥ अस्य श्रीशारिकाभगवतीनामसहस्रस्य, महादेव ऋषिः, त्रिष्टुप्छन्दः,
श्रीशारिकाभगवतीदेवता, शांबीजं, श्रींशक्तिः, फ्रां कीलकं, आत्मने
वाङ्मनः०—श्रीशारिकादेवीप्रसादसिद्ध्यर्थं पाठे होमे वा विनियोगः ॥ श्रां
श्रीं श्रूं श्रैं श्रौं श्रः इतिन्यासः प्राणायामः ॥ ध्यानं ॥ बालार्ककोटिद्युति-
मिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् । सिंहाधिरूढां शिववाम-
देहलीनां भजे चेतसि शारिकेशीम् ॥ मूलं । ॐह्रींश्रींहूंफ्रांआंशांशा-
रिकायैनमः ॥ शारिकायै विद्महे, पञ्चदशाक्षर्यै धीमहि, तन्नः शारी
प्रचोदयात् ३ ॥ ॐह्रींश्रीं हूंफ्रांआंशांश्रीशारिका श्यामसुन्दरी ।
शिला शारी शुकी शान्ता शान्तमानसगोचरा । शान्तिस्था
शान्तिदा शान्तिः श्यामा श्यामपयोधरा । देवी शशाङ्कबिम्बाढ्या
शशाङ्ककृतशेखरा । शशाङ्कशोभिलावण्या शशाङ्कमध्यवासिनी ।
शार्दूलवाहा देवेशी शार्दूलचर्मवासिनी । गौरी पद्मावती पीना

पीनवक्षोजकुड्मला । पीताम्बरा रक्तदन्ता दाडिमीकुसुमप्रभा ।
स्फुरद्रत्नांशुखचिता रत्नमण्डलविग्रहा । रक्ताम्बरधँरा क्षीबा
रत्नमालाविभूषणा । रत्नसंमूर्च्छिताभाऽद्या दीप्ता दीप्तशिखा
दया । दयावती कल्पलता कल्पान्तदहनोपँमा । भैरवी भीम-
नादा च भयानकमुखी भगा । कारा कारुण्यरूपा च भगमा-
लाविभूषणा । भगेश्वरी भगस्था च कुरुकुल्याँ कृशोदरी ।
कादम्बरी कचोत्कृष्टा परमा परमेश्वरी । सती सरस्वती स-
त्याऽसत्या सत्यँस्वरूपिणी । परम्परा पटाकारा पाटला पाटल-
प्रभा । पद्मिनी पद्मवदना पद्मा पद्मकरा शिवा । शिवाश्रँया
शरच्छान्ता शची रम्भा विभावरी । द्युमणिः प्रस्तरा पाठा
पीठेशी पीवराकृतिः । अर्चिंन्त्या मुसलाधारा मातङ्गी मधुर-
स्वना । वीणा गीतप्रिया गाथा गारुडी गरुडध्वजा । अती-
वसुन्दराकारा सुन्दँरी सुन्दरालका । अलका नाकमध्यस्था
नाकिनी नाकपूजिता । पातालेश्वरसंपूज्या पातालतल-
चारिणी । अनन्ताऽनन्तरूपा च स्वज्ञातँा ज्ञानवर्धिनी ।
अमेया चाप्रमेया च ह्यनन्तादित्यरूपिणी । द्वादशादित्यसं-
पूज्या शमी श्यामाकबीजिनी । विभासा भास्वराऽवँर्णा सम-
स्तासुरघातिनी । सुधामयी सुधामूर्तिः सुधा सर्वप्रियङ्करी ।
सुखदा च सुरेशानी कृशानुवल्लभा हविः । स्वाँहा स्वाहेश-
नेत्रा च वह्निवक्त्राग्नितर्पिता । सूर्याग्निसोमनेत्रा च भूर्भुवःस्वः-
स्वरूपिणी । भूमिर्भूदेवसंपूज्या स्वयम्भूः स्वात्मपूजका ।
स्वयम्भूपुष्पमाँलाढ्या स्वयम्भूपुष्पवल्लभा । आनन्दकन्दली
कन्दा स्कन्दमाता शिवालया । शिलारूपा शिलेशानी शिला-

पूजनहर्षिता । चेतना चिद्भवाकारा भवपत्नी भयापहा । विघ्ने-श्वरी गणेशानी गणमाता गणप्रसूः । गणेशमुख्यसम्पूज्या विघ्नविध्वंसिनी निशा । वश्या वश्यजनस्तुत्या स्तुतिः श्रुति-धरा श्रुतिः । श्रुतिशास्त्रविधानज्ञा शास्त्रार्थकोविदा रमा । वेद्या विद्यामयी विद्या विधातृवरदा वधूः । वधूरूपा वधूपूज्या वधूपानप्रतर्पिता । वधूपूजनसन्तुष्टा वधूमालाविभूषणा । वामा वामेश्वरी वाम्या वामाचारप्रियङ्करी । वामाचारा वामदेव-पूज्या वामस्थिताऽर्थदा । वामदेवेश्वरी देवी कुलाकुलविचारि-णी । वितर्कतर्कनिलया प्रलयानलसन्निभा । यज्ञेश्वरी यज्ञमुखा यज्ञाङ्गी यज्ञवर्धिनी । याजकाऽयाजकाऽराध्या यजना यानपा-त्रका । यक्षेश्वरी यक्षदात्री यक्षनायकपूजिता । पर्वतस्था पर्व-तजा पार्वती पर्वताश्रया । पिलम्पिला पदस्थाना पददा नरका-न्तका । नारी नर्मप्रिया श्रीदा श्रीदश्रीदा शतायुधा । कामे-श्वरी रतिर्हूतिराहुतिर्हव्यवाहना । हरेश्वरी हरवधूर्हाटकाङ्गद-मण्डिता । पुरुष्या स्वर्गतिर्वैद्या सुमुखा च महौषधिः । सर्व-रोगहरा माध्वी मधुपानपरायणा । मधुस्थिता मधुमयी मद-दानविशारदा । मधुतृप्ता मधुरूपा मधूककुसुमप्रभा । माधवी माधवीवल्ली मधुमत्ता मदालसा । मारप्रिया मारपूज्या मारदेव-प्रियङ्करी । मारेशी च मृत्युहरा हरकान्ता मनोन्मना । महा-वैद्यप्रिया वैद्या वैद्याचारा सुरार्चिता । सुरेशी सुरसंपूज्या सुरमान्या सुरेश्वरी । सुरापानरता साध्वी पात्रसिद्धिप्रदायिनी । सामन्ता पीनवपुषी गुटी गुर्वी गरीयसी । कालान्तका कालमुखी कठोरा करुणामयी । नीला नाडी च वागीशी दूर्वा-

ख्याता सरस्वती । अपारपारगा गम्या गतिः प्रीतिः पयोधरा । पयोदसदृशच्छाया पारदाऽऽकृतिरालसा । सरोजनिलया नीतिः कीर्तिः कीर्तिकरी कथा । काशी काम्या कपर्दाऽर्शां काश-पुष्पोपमा रमा । रामा रामप्रिया रामभद्रा देवसमर्चिता । रामसम्पूजिता रामसिद्धिदा रामकार्यदा । रामभद्रार्चिता रेवा देवकी देववत्सला । देवपूज्या देववन्द्या देवदानवचर्चिता । द्रुतिर्द्रुतगतिर्दम्भा दामिनी विजया जया । अशेषसुरसम्पूज्या निःशेषासुरसूदिनी । वटिनी वटमूलस्था लास्यहास्यैकवल्लभा । अरूपा निर्गुणा सत्या सदासन्तोषवर्धिनी । सौम्या यजुर्वहा याम्या यमुना यामिनी यमी । क्षमा दक्षा वराम्बोधिर्दाल्भ्य-सेव्या दरी पुरी । पौरन्दरी पुलोमेशी पौलोमी पुलकाङ्कुरा । पुरस्था वनभूर्वन्या वानरी वनचारिणी । समस्तवर्णनिलया समस्तवर्णपूजिता । समस्तवर्णवर्णाढ्या समस्तगुरुवत्सला । समस्तमुण्डमालाढ्या मालिनी मधुपस्वना । कोशप्रदा कोशवासा चमत्कृतिरलम्बुसा । हास्यदा सदसद्रूपा सर्ववर्णमयी स्मृतिः । सर्वाक्षरमयीविद्या मूलविद्याविदीश्वरी । अकारा षोडशाकारा का-राबन्धविमोचिनी । ककारव्यञ्जनाक्रान्ता सर्वमन्त्राऽक्षरालया । अमाऽणुरूपा विमला त्रैगुण्या चापराजिता । अम्बिकाऽम्बा-लिकाचाऽम्बाप्यनन्तगुणमेखला । अपर्णा पर्णशाला च सा-ट्टहासा हसन्तिका । हसन्ती च हस्तिमुखा हस्तिपादा मनो-रमा । अद्रिकन्याऽट्टहासा च त्वजरास्याप्यरुन्धती । अब्जाक्षी त्वब्जिनीदेवी चाम्बुजासनसंस्थिता । अब्जहस्ताऽब्जपादा च त्वब्जपूजनतोषिता । अकारमातृकादेवी सर्वानन्दकरी कला ।

पूजनहर्षिता । चेतना चिद्भवांकारा भवपत्नी भयापहा । विघ्नेश्वरी गणेशानी गणमाता गणप्रसूः । गणेशमुख्यसम्पूज्या विघ्नविध्वंसिनी निशा । वश्यां वश्यजनस्तुत्या स्तुतिः श्रुतिधरा श्रुतिः । श्रुतिशास्त्रविधानज्ञा शास्त्रार्थकोविदा रमा । वेद्या विद्यामयी विद्यां विधातृवरदा वधूः । वधूरूपा वधूपूज्या वधूपानप्रतर्पिता । वधूपूजनसन्तुष्टा वधूमालाविभूषणा । वामा वामेश्वरी वाम्यां वामाचारप्रियङ्करी । वामाचारा वामदेवपूज्या वामस्थिताऽर्थदा । वामदेवेश्वरी देवी कुलाकुलविचारिणी । वितर्कतर्कनिलया प्रलयानलसन्निभा । यज्ञेश्वरी यज्ञमुखा यज्ञाङ्गी यज्ञवर्धिनी । याजकाऽयाजकाऽराध्या यजना यानपात्रका । यक्षेश्वरी यक्षदात्री यक्षनायकपूजिता । पर्वतस्था पर्वतजा पार्वती पर्वताश्रया । पिलम्पिला पदस्थाना पददा नरकान्तका । नारी नर्मप्रिया श्रीदा श्रीदश्रीदा शतायुधा । कामेश्वरी रतिर्हूतिराहुतिर्हव्यवाहना । हरेश्वरी हरवधूर्हाटकाङ्गदमण्डिता । पुरुष्या स्वर्गतिर्वैद्या सुमुखा च महौषधिः । सर्वरोगहरा माध्वी मधुपानपरायणा । मधुस्थिता मधुमयी मददानविशारदा । मधुरसा मधुरूपा मधूककुसुमप्रभा । माधवी माधवीवल्ली मधुमत्ता मदालसा । मारप्रिया मारपूज्या मारदेवप्रियङ्करी । मारेशी च मृत्युहरा हरकान्ता मनोन्मना । महावैद्यप्रिया वैद्या वैद्याचारा सुरार्चिता । सुरेशी सुरसंपूज्या सुरमान्या सुरेश्वरी । सुरापानरता साध्वी पात्रसिद्धिप्रदायिनी । सामन्ता पीनवपुषी गुटी गुर्वी गरीयसी । कालान्तका कालमुखी कठोरा करुणामयी । नीला नादी च वागीशी दूर्वा-

ख्याता सरस्वती। अपारपारगा गम्या गतिः प्रीतिः पयोधरा। पयोदसदृशच्छाया पारदाऽऽकृतिरालसा। सरोजनिलया नीतिः कीर्तिः कीर्तिकरी कथा। काशी काम्या कपर्दाऽऽशा काशपुष्पोपमा रमा। रामा रामप्रिया रामभद्रा देवसमर्चिता। रामसम्पूजिता रामसिद्धिदा रामकार्यदा। रामभद्रार्चिता रेवा देवकी देववत्सला। देवपूज्या देववन्द्या देवदानवचर्चिता। द्युतिर्द्रुतगतिर्दम्भा दामिनी विजया जया। अशेषसुरसम्पूज्या निःशेषासुरसूदिनी। वटिनी वटमूलस्था लास्यहास्यैकवल्लभा। अरूपा निर्गुणा सत्या सदासन्तोषवर्धिनी। सौम्या यजुर्वहा याम्या यमुना यामिनी यमी। क्षमा दक्षा वराम्बोधिर्दालभ्यसेव्या दरी पुरी। पौरन्दरी पुलोमेशी पौलोमी पुलकाङ्कुरा। पुरस्था वनभूर्वन्या वानरी वनचारिणी। समस्तवर्णनिलया समस्तवर्णपूजिता। समस्तवर्णवर्णाढ्या समस्तगुरुवत्सला। समस्तमुण्डमालाढ्या मालिनी मधुपस्वना। कोशप्रदा कोशवासा चमत्कृतिरलम्बुसा। हास्यदा सदसद्रूपा सर्ववर्णमयी स्मृतिः। सर्वाक्षरमयीविद्या मूलविद्याविदीश्वरी। अकारा षोडशाकारा कारावन्धविमोचिनी। ककारव्यञ्जनाक्रान्ता सर्वमन्त्राऽक्षरालया। अमाऽणुरूपा विमला त्रैगुण्या चापराजिता। अम्बिकाऽम्बालिकाचाऽम्बाप्यनन्तगुणमेखला। अपर्णा पर्णशाला च साट्टहासा हसन्तिका। हसन्ती च हस्तिमुखा हस्तिपादा मनोरमा। अद्रिकन्याऽट्टहासा च त्वजरास्याप्यरुन्धती। अब्जाक्षी त्वब्जिनीदेवी चाम्बुजासनसंस्थिता। अब्जहस्ताऽब्जपादा च त्वब्जपूजनतोषिता। अकारमातृकादेवी सर्वानन्दकरी कला।

आनन्दसुन्दरी चार्या चाघूर्णारुणलोचना । आंदिदेवाऽन्तक-क्रूरा चादित्यकुलभूषणा । आंबीजमण्डलादेवी त्वाकारमातृ-कावलिः । इन्द्रस्तुतेन्दुबिम्बास्या त्विनकोटिसमप्रभा । इन्दिरा मन्दिरा शैंला चेतिहासकथा मतिः । इलेक्षुरसदाऽ-स्वादा त्विकाराक्षरभूषिता । इन्द्रस्तुतेन्द्रसंपूज्या त्विनभद्रा त्विनेश्वरी । इभस्थितिरिभांगीना चेकाराक्षरमातृका । ईश्वरी वैभवख्याता चेशानीश्वरवल्लभा । ईशा कामकला चैन्द्री त्वीकाराक्षरमातृका । उग्रप्रभोग्रचिन्तोग्रवामाङ्गवासिनी त्वुषा। उग्रा वैष्णवसंपूज्या चोग्रतारोल्मुकानना । उँमेश्वरी गुणश्रे-ष्ठोस्रोदेश्वर्युदकप्रिया । उदकाच्छोदकदात्री चोकारोद्भवमा-तृका । ऊष्मोषा चोर्ष्णा सीता दितिराऽदित्यसुप्रभा । ऋण-हर्त्री ह्यृणर्णेशी ॠलवर्णा लृवर्णभाक् । लृकारा भ्रुंकुटिर्बाल-बालादित्यसमप्रभा । एनाङ्कमुकुटेहात्मा चैकाराक्षरबीजिता । एनप्रियैनाङ्कमध्यस्थितैनमध्यवासिनी । एनेद्रवत्सला ऐंचैनी चैकारोद्भासमातृका । ओकारशेखराभासा त्वौचित्या मदम-ण्डिता । अम्भोजनिलया स्वस्था अःस्वरूपा चिदात्मिका । षोडशस्वररूपा च षोडशस्वरगाँयनी । षोडशी षोडशाकारा कमला कमलोद्भवा । कामेश्वरी कलाभिज्ञा कुमारी कुटिला-लका । कुटिला कुटिलाँकारा कुटुम्बिनी कृतिः शिवा । कुला-कुलोपदेशानी कुलेशी कुब्जिका कला । कामा कामप्रिया कीरीं कमनीया कपालिनी । कालिका भद्रकाली च काला कामा-न्तकारिणी । कपर्दिनी कपालेशी कर्पूरचयचर्चिता । काद-म्बरी कोमलाङ्गी काश्मीरी कुङ्कुमद्युतिः । कुन्ता कूर्चाऽग्रबी-

जाड्या कमनीया कुलाकुला । करालास्या करांलाक्षी कामिनी कामपालिनी । कन्थाधरा कृपाकर्त्री ककाराक्षरमातृका । खड्गहस्ता खर्परेशी खेचरी खगगामिनी । खेचरीमुद्रयायुक्ता खेचरत्वप्रदायिनी । खगासना खलोलाक्षी खेटेशी खलनाशिनी । खेटकायुधहस्ता च खरांशुद्युतिसन्निभा । खाता खबीजनिलया खकारोल्लासमातृका । वैखरी बीजनिलया खस्था खेचरवल्लभा । गुण्या गजास्यजननी गणेशवरदा गया । गोदावरी गदाहस्ता गदाधरप्रिया गतिः । गीता गोवाहनेशानी गरलाशनविग्रहा । गाम्भीर्यभूषणा गङ्गा गायत्री गजवाहना । घोनां घोनाकरस्तुत्या घुर्घुरा घोरनादिनी । घटस्था घटजसेव्या घटपूजनलोलुपा । घटामयरसप्रीता घनरूपा घनेश्वरी । घनवाहनसेव्या च घकाराक्षरमातृका । ङान्ता ङवर्णनिलया ङानुरूपा ङनालया । ङेज्ञानिनी ङनाजाप्या ङवर्णाक्षरमातृका । चामीकररुचिश्चान्द्री चन्द्रिका चन्द्ररागिणी । चला चेला चञ्चला च चञ्चरीकालकप्रभा । चञ्चरीकस्वरालापा चमत्कारस्वरूपिणी । चट्टुला चार्वङ्की चार्वी चम्पा चम्पकसन्निभा । चीनांशुकधरा चित्रा चकाराक्षरमातृका । छत्री छत्रधराच्छन्ना छिन्नमस्ता च्छुरच्छविः । छायासुतप्रिया छाया छवर्णामलमातृका । जगदम्बा जगज्ज्योतिर्ज्योतीरूपा जटाधरा । जयदा जयकर्त्री च जयस्था जयहासिनी । जयेशी जयधर्त्री च जगत्कर्त्री जगत्प्रिया । जगत्पूज्या जगद्वासा जगद्रक्षा जरातुरा । ज्वरघ्नी जम्भदमनी जगत्प्राणा जयावहा । जैत्रा जम्भारिवरदा जीवना जीववाक्प्रदा । जागृतिश्च जगन्निद्रा जगद्योनिर्जल-

न्धरा । जालन्धरजया जाया जकाराक्षरमातृका । झम्पा झिञ्झेश्वरी झान्ता झकाराक्षरमातृका । ञानुरूपा ञिनावींसा ञकारेशी ञणायुधा । ञवर्णबीजभूषाढ्या ञकाराक्षरमातृका । टङ्कायुधा टकाराढ्या टोटाक्षी टसुकुन्तला । टङ्काश्रया टलीरूपाँ टकाराक्षरमातृका । ठकुरा ठकुरेशानी ठकारत्रितयेश्वरी । ठस्वरूपा ठवर्णाढ्या ठकाराक्षरमातृका । डक्का डकेश्वरी डिम्बाँ डवर्णाक्षरमातृका । ढिणी ढेया ढिल्लहस्ता ढकाराक्षरमातृका । णेशा णान्ता णवर्णात्मा णकाराक्षरभूषणा । तुंरी तुर्या तुलारूपा त्रिपुरा तामसप्रिया । तोतुला तारिणी तारासप्तविंशतिरूपिणी । त्रिस्वरा त्रिगुणिध्येया त्र्यम्बकेशी त्रिलोकधृत् । त्रिवर्गेशा त्रयी त्र्यक्षा त्रिपदा त्रेतरूपिणी । त्रिलोकजननी त्रेता त्रिपुरेश्वरपूजिता । त्रिकोणस्थाँ त्रिकोणेशीं त्रिकोणान्तर्निवासिनी । त्रिकोणपूजनतुष्टा त्रिकोणपूजनप्रिया । वसुकोणस्थिता वश्या वसुकोणार्थवादिनी । वसुकोणासनेसंस्था षट्चक्रक्रमपूजिता । नागपत्रस्थिंता शारी त्रिवृत्तपूजनार्थदा । चतुर्द्वाराग्रगा चक्रबाह्यान्तरनिवासिनी । तामसी तुम्बुरुस्तुत्या तोमरायुधमण्डिता । तुलाकोटिस्वना तापी तपसःफलँदायिनी । तरिस्तरणिरूपा च तारकासुरघातिनी । तरलाक्षी तमोहन्त्री तकाराक्षरमातृका । स्थली स्थविररूपा च स्थूला स्थाली स्थलाब्जिनी । स्थविरेशी स्थूलमुखी थकाराक्षरमातृका । दूतिका शिवदूती च दण्डायुधधरा द्युतिः । दीपा दीनानुकम्पा च दम्भोलिधरवल्लभा । देशानुचारिणी द्रेक्का द्राविडेशी द्वीयसी । दाक्षायणी द्रुमलता देवमाताऽदिदेवता । दधिजा दुर्लभादेवी

देवता परमाक्षरा । दामोदरसुपूज्या च दामोदरवरप्रदा । दण्डहस्ता दण्डिपूज्या दकारक्षरमातृका । धर्म्या च धर्ममूर्धन्याँ धनदा धनवर्धिनी । धृतिर्धूर्ता धन्यवधूर्धकाराक्षरमातृका । नलिनी नलिनहस्ता नाराचायुधधारिणी । नीपोपवँनमध्यस्था नगरेशी नरोत्तमा । नरेश्वरी नृपाराध्या नृपपूज्या नृपार्थदा । नृपसेव्या नृपवन्द्या नरनारायणप्रसूः । नँर्तकी नीरजाक्षी च नवर्णाक्षरभूषणा । पद्मेश्वरी पद्ममुखी पत्रियाना परापरा । पारावतसुता पेया परवर्गविमर्दिनी । त्रिँपुंरारिवधूः पम्पा पत्री पत्रीशवाहना । पीवरांसा पतिप्राणा पीतलाक्षी पतिप्रिया । पाठा पीठस्थिता पीतवस्त्रालङ्कांरंभूषणा । पुरूरवस्तुता पात्री पुत्रिका पुत्रदा प्रजा । पुष्पोत्तमा पुष्पवती पुष्पमालाविभूषिता । पुष्पमालाधिशोभाढ्या पकाराक्षरमाँतृका । फलदा स्फीतवस्त्रा च फेरुरावविभूषणा । फल्गुनी फल्गुतीर्थस्था फवर्गाकृतमण्डना । वलदा बालखिल्या च बाला बँलंरिपुप्रिया । बाल्यावस्था बन्धरेशी बकाराकृतिमातृका । भद्रिका भीमपत्नी च भीमा भर्गशिखाऽभया । भयघ्नी भीमनादाँ च भयानकमुखेक्षणा । भिल्लेश्वरी भीतिहरा भद्रदा भाग्यवर्धिनी । भगमाला भगावासा भवानी भवतारिणी । भर्गंयोनिर्भगाकारा भगस्था भगरूपिणी । भगलिङ्गामृतप्रीता भकाराक्षरमातृका । मान्या मानप्रदा मीना मीनकेतनलालसा । मदोद्धँता मनोतीता मेना मैनाकवत्सला । मांसाहारा मांसप्रीता मत्स्यघाता महत्तरा । मेरुशृङ्गाग्रतुङ्गस्था मोदकाहारपूजिता । मँातङ्गिनी मदोन्मत्ता मधुमत्ता मठेश्वरी । मज्जा मुग्धानना मुग्धा मकाराक्षरभूषणा ।

यशस्विनी यतीशानी यत्नकर्त्री यजुःप्रिया । यज्ञदात्री यज्ञफल
यजुर्वेदफला यतिः । यशोदा यतिसेव्या च यात्रा यात्रिक
वत्सला ! योगीश्वरी योगगम्या योगीन्द्रजनवत्सला । यदुपुत्री
यमघ्नी च यकाराक्षरमातृका । रत्नेश्वरी रमानाथसेव्या रथ्या
रजस्वला । राज्यदा राजराजेशी रोगहर्त्री रजोवती । रत्नाकर-
सुता रम्या रात्री रात्रीपतिप्रभा । रक्षोघ्नी राक्षसेशानी रक्षो-
नाथसमर्चिता । रतिप्रिया रतिसुखा रकारकृतशेखरा । लम्बो-
दरी ललज्जिह्वा लास्यतत्परमानसा । लूतातन्तुवितानास्था
लक्ष्मीर्लज्जालयाऽलिनी । लोकेश्वरी लोकदात्री लाटस्था लक्ष्म-
णाकृतिः । लम्बा लम्बकचोल्लासा लकाराक्षरवर्धिनी । लिङ्ग-
प्रीता कलिङ्गेशी लिङ्गस्था लिङ्गलिङ्गिनी । लक्ष्मीरूपा रसो-
ल्लासा रामा रेवा रजोवती । लयदा लक्ष्मणा लोला लकाराक्ष-
रमातृका । वाराही वरदात्री च वीरसूर्वरदायिनी । वीरेश्वरी
वीरजन्या वरचर्वणचर्चिता । वरायुधा वराका च वामना वा-
मनाकृतिः । वधूता वधकावध्या वध्यभूर्वणिजप्रिया । वसन्त-
लक्ष्मीर्वटुकी वटुका वटुकेश्वरी । वटुप्रिया वामनेत्रा वामाचारैक-
लालसा । वात्या वाम्या वरारोहा वेदमाता वसुन्धरा । वयो-
याना वयस्था च वकाराक्षरमातृका । शम्भुप्रिया शरच्चर्चा
शाद्वला शशिवत्सला । शीतद्युतिः शीतरसा शोणोष्ठी शीकर-
प्रभा । श्रीवत्सलाञ्छना शर्वा शर्ववामाङ्गवासिनी । शशाङ्का-
मलशोभाढ्या शार्दूलतनुरद्रिजा । शेषहर्त्री शमीमूला शकार-
कृतशेखरा । षोडशाक्षरमन्त्रेशी षाढा षोडा षडानना । षट्कूटा
षड्रसास्वादा षडशीतिमुखाम्बुजा । षडास्यजननी षष्ठा षवर्णा-

क्षरमातृका। सरस्वतीप्रसूः सर्वा सर्वगा सर्वतोमुखा। समा सीमा सतीमाता सागराभयदायिनी। समस्तपापशमनी सालभञ्जी सुदक्षिणा। सुषुप्तिः सरसा साध्वी सामगा सामवेदजा। सत्यप्रिया सोमसुखी सूत्रस्था सूतवल्लभा। सनकेशी सुनन्दा च सवर्णा स्वास्थ्यदायिनी हाहाहूहूस्वरूपा च हलदात्री हलिप्रिया। हंक्षःस्वरूपानुगता सर्वमातृकपूजिता। हरिदीश्वरपूज्यात्मा हविष्याहुतिवल्लभा। ॐऐंसौःह्रींमहाविद्या आंशांहांहूंस्वरूपिणी १००० ॥ इति सहस्रनामस्तुतिः ॥ अथ सहस्रनामावली ॥

ॐ ह्रींश्रींहूंफ्रांआंशांश्रीशारिकायैस्वाहा, श्यामसुन्दर्यै, शिलायै, शार्यै, शुक्यै, शान्तायै, शान्तमानसगोचरायै, शान्तिस्थायै, शान्तिदायै, शान्त्यै, श्यामायै, श्यामपयोधरायै, देव्यै, शशाङ्कविम्बाढ्यायै, शशाङ्ककृतशेखरायै, शशाङ्कशोभिलावण्यायै, शशाङ्कमध्यवासिन्यै, शार्दूलवाहायै, देवेश्यै, शार्दूलचर्मवासस्यै, गौर्यै, पद्मावत्यै, पीनायै, पीनवक्षोजकुड्मलायै, पीताम्बरायै, रक्तदन्तायै, दाडिमीकुसुमप्रभायै, स्फुरद्रत्नांशुखचितायै, रत्नमण्डलविग्रहायै, रक्ताम्बरधरायै, क्षीवायै, रत्नमालाविभूषणायै, रत्नसंमूर्छिताभायै, आद्यायै, दीप्तायै, दीप्तशिखायै, दयायै, दयावत्यै, कल्पलतायै, कल्पान्तदहनोपमायै, भैरव्यै, भीमनादायै, भयानकमुख्यै, भगायै, कारायै, कारुण्यरूपायै, भगमालाविभूषणायै, भगेश्वर्यै, भगस्थायै, कुरुकुल्यायै, कृशोदर्यै, कादम्बर्यै, कचोत्कृष्टायै, परमायै, परमेश्वर्यै, सत्यै, सरस्वत्यै, सत्यायै, असत्यायै, सत्यस्वरूपिण्यै, परम्परायै, पटाकारायै, पाटलायै, पाटलप्रभायै, पद्मिन्यै, पद्मवदनायै, पद्मायै, पद्मकरायै, शिवायै,

शिवाश्रंयायै, शरच्छान्तायै, शच्यै, रम्भायै, विभावर्यै, द्युमणये, प्रस्तरायै, पाठायै, पीठेश्यै, पीवराकृतये, अचिन्त्यांयै, मुसलाधारायै, मातङ्ग्यै, मधुरस्वनायै, वीणायै, गीतप्रियायै, गाथायै, गारुड्यै, गरुडध्वजायै, अतीवसुन्दराकारायै, सुंन्दर्यै, सुन्दरालकायै, अलकायै, नाकमध्यस्थायै, नाकिन्यै, नाकपूजितायै, पातालेश्वरसंपूज्यायै, पातालतलचारिण्यै, अनन्तायै, अनन्तरूपायै, तेजोसि स्वज्ञातांयै, ध्यानं। ॐज्ञानवर्धिन्यैस्वाहा, अमेयायै, अप्रमेयायै, अनन्तादित्यरूपिण्यै, द्वादशादित्यसंपूज्यायै, शम्यै, शामाकवीजिन्यै, विभासायै, भास्वरायै, अंवर्णायै, समस्तासुरघातिन्यै, सुधामय्यै, सुधामूर्तये, सुधायै, सर्वप्रियङ्कर्यै, सुखदायै, सुरेशान्यै, कृशानुवल्लभायै, हविषे, स्वाहांयै, स्वाहेशनेत्रायै, वह्निवक्त्रायै, अग्नितर्पितायै, सूर्याग्निसोमनेत्रायै, भूर्भुवःस्वःस्वरूपिण्यै, भूम्यै, भूदेवसंपूज्यायै, स्वयम्भुवे, स्वात्मपूजकायै, स्वयम्भूपुष्पमालाढ्यायै, स्वंयम्भूपुष्पवल्लभायै, आनन्दकन्दल्यै, कन्दायै, स्कन्दमात्रे, शिवालयायै, शिलारूपायै, शिलेशान्यै, शिलापूजनहर्षितायै, चेतनायै, चिद्भवाकांरायै, भवपत्न्यै, भयापहायै, विघ्नेश्वर्यै, गणेशान्यै, गणमात्रे, गणप्रस्वै, गणेशमुख्यसम्पूज्यायै, विघ्नविध्वंसिन्यै, निशायै, वश्यांयै, वश्यजनस्तुत्यायै, स्तुतये, श्रुतिधरायै, श्रुतये, श्रुतिशास्त्रविधानज्ञायै, शास्त्रार्थकोविदायै, रमायै, वेद्यायै, विद्यामय्यै, विद्यांयै, विधातृवरदायै, वध्वै, वधूरूपायै, वधूपूज्यायै, वधूपानप्रतर्पितायै, वधूपूजनसन्तुष्टायै, वधूमालाविभूषणायै, वामायै, वामेश्वर्यै, वाम्यायै, वामाचारप्रियङ्कर्यै, वामाचारायै, वामदेवपूज्यायै, वामस्थितायै, अर्थदायै, वाम-

देवेश्वरीदेव्यै, कुलाकुलविचारिण्यै, वितर्कतर्कनिलयायै, प्रलयानलसन्निभायै, यज्ञेश्वर्यै, यज्ञमुखायै, यज्ञाङ्ग्यै, यज्ञवर्धिन्यै, याजकायै, अयाजकायै, आराध्यायै, यजनायै, यानपात्रकायै, यक्षेश्वर्यै, यक्षदात्र्यै, यक्षनायकपूजितायै, पर्वतस्थायै, पर्वतजायै, पार्वत्यै, पर्वताश्रयायै, पिलम्पिलायै, पदस्थानायै, पददायै, नरकान्तकायै, तेजोसि ॐनायैस्वाहीं ध्यानं नर्मप्रियायै, श्रीदायै, श्रीदश्रीदायै, शतायुधायै, कामेश्वर्यै, रत्यै, हूत्यै, आहुत्यै, हव्यवाहनायै, हरेश्वर्यै, हरवध्वै, हाटकाङ्गदमण्डितायै, पुरुष्यायै, स्वर्गतये, वैद्यायै, सुमुखायै, महौषधये, सर्वरोगहरायै, माध्व्यै, मधुपानपरायणायै, मधुस्थितायै, मधुमय्यै, मददानविशारदायै, मधुतृप्तायै, मधुरूपायै, मधूककुसुमप्रभायै, माधव्यै, माधवीवल्ल्यै, मधुमत्तायै, मदालसायै, मारप्रियायै, मारपूज्यायै, मारदेवप्रियङ्कर्यै, मारेश्यै, मृत्युहरायै, हरकान्तायै, मनोन्मनायै, महावैद्यप्रियायै, वैद्यायै, वैद्याचार्यायै, सुरार्चितायै, सुरेश्यै, सुरसंपूज्यायै, सुरमान्यायै, सुरेश्वर्यै, सुरापानरतायै, साध्व्यै, पात्रसिद्धिप्रदायिन्यै, सामन्तायै, पीनवपुष्यै, गुर्व्यै, गुर्व्यै, गरीयस्यै, कालान्तकायै, कालमुख्यै, कठोरायै, करुणामय्यै, नीलायै, नाव्यै, वागीश्यै, दूर्वाख्यातायै, सरस्वत्यै, अपारपारगायै, गम्यायै, गतये, प्रीत्यै, पयोधरायै, पयोदसदृशच्छायायै, पारदायै, आकृत्यै, आलसायै, सरोजनिलयायै, नीत्यै, कीर्त्यै, कीर्तिकर्यै, कथायै, काश्यै, काम्यायै, कपर्दायै, आशायै, काशपुष्पोपमायै, रमायै, रामायै, रामप्रियायै, रामभद्रायै, देवसमर्चितायै, रामसम्पूजितायै, रामसिद्धिदायै, राम-

कार्यदायै, रामभद्रार्चितायै, रेवायै, देवक्यै, देववत्सलायै, देवपूज्यायै, देववन्द्यायै, देवदानवचर्चितायै, द्रुतये, द्रुतगतये, दम्भायै, "तेजोसि" दमन्यै ३०० ॥ ध्यानं ॥ ॐविजयायैस्वाहा, जयायै, अशेषसुरसम्पूज्यायै, निःशेषासुरसूदिन्यै, वटिन्यै, वटमूलस्थायै, लास्यहास्यैकवल्लभायै, अरूपायै, निर्गुणायै, सत्यायै, सदासन्तोषवर्धिन्यै, सौम्यायै, यजुर्वहायै, याम्यायै, यमुनायै, यामिन्यै, यम्यै, क्षमायै, दक्षायै, वराम्भोधये, दाल्भ्यसेव्यायै, दर्यै, पुर्यै, पौरन्दर्यै, पुलोमेश्यै, पौलोम्यै, पुलकाङ्कुरायै, पुरस्थायै, वनभुवे, वन्यायै, वानयै, वनचारिण्यै, समस्तवर्णनिलयायै, समस्तवर्णपूजितायै, समस्तवर्णवर्णाढ्यायै, समस्तगुरुवत्सलायै, समस्तमुण्डमालाढ्यायै, मालिन्यै, मधुपस्वनायै, कोशप्रदायै, कोशवासायै, चमत्कृत्यै, अलम्बुसायै, हास्यदायै, सदसद्रूपायै, सर्ववर्णमय्यै, स्मृत्यै, सर्वाक्षरमयीविद्यायै, मूलविद्यायै, विश्वेश्वर्यै, अकारायै, षोडशाकारायै, काराबन्धविमोचिन्यै, ककारव्यञ्जनाक्रान्तायै, सर्वमन्त्रायै, अक्षरालयायै, अमायै, अणुरूपायै, विमलायै, त्रैगुण्यायै, अपराजितायै, अम्बिकायै, अम्बालिकायै, अम्बायै, अनन्तगुणमेखलायै, अपर्णायै, पर्णशालायै, साट्टहासायै, हसन्तिकायै, हँसन्त्यै, हस्तिमुखायै, हस्तिपादायै, मनोरमायै, अद्रिकन्यायै, अट्टहासायै, अजरास्यायै, अरुन्धत्यै, अब्जाक्ष्यै, अब्जिनीदेव्यै, अम्बुजासनसंस्थितायै, अब्जहस्तायै, अब्जपादायै, अब्जपूजनतोषितायै, अकारमातृकादेव्यै, सर्वानन्दकर्यै, कलायै, आनन्दसुन्दर्यै, आर्यायै, आघूर्णारुणलोचनायै, आदिदेवायै, अन्तकक्रूरायै, आदित्यकुलभूषणायै, आंबीज-

मण्डलादेव्यै, आकारमातृकावलये, इन्द्रस्तुतायै, इन्दुविम्बास्यायै, इनकोटिसमप्रभायै, इन्दिरायै मन्दिरायै, "तेजोसि" ॐ शालायैस्वाहाँ ध्यानं ॥ ॐइतिहासकथायैस्वाहा, मत्यै, इलायै, इक्षुरसदायै, आस्वादायै, इकाराक्षरभूषितायै, इन्द्रस्तुतायै, इन्द्रसंपूज्यायै, इनभद्रायै, इनेश्वर्यै, इभस्थितये, इभांगीनायै, इकाराक्षरमातृकायै, ईश्वर्यै, वैभवख्यातायै, ईशान्यै, ईश्वरवल्लभायै, ईशायै, कामकलायै, ऐन्द्र्यै, ईकाराक्षरमातृकायै, उग्रप्रभायै, उग्रचिन्तायै, उग्रवामाङ्गवासिन्यै, उषायै, उग्रायै, वैष्णवपूज्यायै, उग्रतारायै, उल्मुकाननायै, उमेश्वर्यै, गुणश्रेष्ठायै, उस्रायै, उदेश्वर्यै, उदकप्रियायै, उदकाच्छायै, उदकदात्र्यै, उकारोद्भवमातृकायै, ऊष्मायै, ऊषायै, ऊषर्णायै, सीतायै, दित्यै, आदित्यसुप्रभायै, ऋणहर्त्र्यै, ऋणायै, ऋणेश्यै, ऋलवर्णायै, लृवर्णभाजे, लृकारायै, भ्रुकुटये, बालायै, बालादित्यसमप्रभायै, एनाङ्गमुकुटायै, ईहात्मने, एकाराक्षरबीजितायै, एनप्रियायै, एनाङ्कमध्यस्थितायै, एनमध्यवासिन्यै, एनेन्द्रवत्सलायै, ऐन्यै, एकारोद्भासमातृकायै, ओकारशेखराभासायै, औचित्यायै, मदमण्डितायै, अम्भोजनिलयायै, स्वस्थायै, अःस्वरूपायै, चिदात्मिकायै, षोडशस्वररूपायै, षोडशस्वरगायन्यै, षोडश्यै, षोडशाकारायै, कमलायै, कमलोद्भवायै, कामेश्वर्यै, कलाभिज्ञायै, कुमार्यै, कुटिलालकायै, कुटिलायै, कुटिलाकारायै, कुटुम्बिन्यै, कृत्यै, शिवायै, कुलाकुलोपदेशान्यै, कुलेश्यै, कुब्जिकायै, कलायै, कामायै, कामप्रियायै, कीरायै, कमनीयायै, कपालिन्यै, कालिकायै, भद्रकाल्यै, कालायै, कामान्तकारिण्यै, कपर्दिन्यै, कपा-

लेश्यै, कर्पूरचयचर्चितायै, तेजोसि ॐकाद्रूमैंयैंस्वाहा ॥ ध्यानं ॥
कोमलाङ्ग्यै, काश्मीर्यै, कुंकुमद्युतये, कुन्तायै, कूर्चायै, आद्य-
बीजाढ्यायै, कमनीयायै, कुलाकुलायै, करालास्यायै, करा-
लाक्ष्यै, कामिन्यै, कामपालिन्यै, कन्थाधरायै, कृपाकर्त्र्यै,
ककाराक्षरमातृकायै, खड्गहस्तायै, खर्परेश्यै, खेचर्यै, खगगा-
मिन्यै, खेचरीमुद्रयाँयुक्तायै, खेचरत्वप्रदायिन्यै, खगासनायै,
खलोलाक्ष्यै, खेटेश्यै, खलनाशिन्यै, खेटकायुधहस्तायै, खरां-
शुद्युतिसन्निभायै, खातायै, खबीजनिलयायै, खकारोंह्लींसमा-
तृकायै, वैखर्यै, बीजनिलयायै, खस्थायै, खेचरवल्लभायै, गु-
ण्यायै, गजास्यजनन्यै, गणेशवरदायै, गयायै, गोदावर्यै,
गदाँहस्तायै, गदाधरप्रियायै, गत्यै, गीतायै, गोवाहनेशान्यै,
गरलाशनविग्रहायै, गाम्भीर्यभूषणायै, गङ्गायै, गायत्र्यै, गज-
वाहनायै, घोणाँयै, घोणाकरस्तुत्यायै, घुर्घुरायै, घोरनादिन्यै,
घटस्थायै, घटजसेव्यायै, घटपूजनलोलुपायै, घटामयरसप्री-
तायै, घनरूपायै, घनेश्वर्यै, घनवाहँनसेव्यायै, घकाराक्षरमातृ-
कायै, ङान्तायै, ङवर्णनिलयायै, ङानुरूपायै, ङनालयायै,
ङेज्ञानिन्यै, ङनाजाप्यायै, ङवर्णाक्षरमातृकायै, चामीकररुचये,
चाँन्द्र्यै, चन्द्रकायै, चन्द्ररागिण्यै, चलायै, चेलायै, चञ्चलायै,
चञ्चरीकालकप्रभायै, चञ्चरीकस्वरालापायै, चमत्कारस्वरूपिण्यै,
चटुलायै, चाँटुक्यै, चार्व्यै, चम्पायै, चम्पकसन्निभायै, चीं-
नांशुकधरायै, चित्रायै, चकाराक्षरमातृकायै, छत्र्यै, छत्रध-
राच्छन्नायै, च्छिन्नमस्तायै, च्छुरच्छवँये, छायासुतप्रियायै, च्छा-
यायै, च्छवर्णामलमातृकायै, जगदम्बायै, जगज्ज्योतिषे, ज्यो-

तीरूपायै, जटाधरायै, जयदायै, जयकर्त्र्यै, तेजोसि ॐजयस्थायैस्वाहां ॥ ध्यानं ॥ जयहासिन्यै, जयेश्यै, जयधर्त्र्यै, जगत्कर्त्र्यै, जगत्प्रियायै, जगत्पूज्यायै, जगद्वासायै, जगद्रक्षायै, जरातुरायै, ज्वरघ्न्यै, जम्भदमन्यै, जगत्प्राणायै, जयावहायै, जैत्रायै, जम्भारिवरदायै, जीवनायै जीववाक्प्रदायै, जाग्रत्यै, जगन्निद्रायै, जंगद्योनये, जलन्धरायै, जालन्धरजयायै, जायायै, जकाराक्षरमातृकायै, झम्पायै, झिञ्झेश्वर्यै, झान्तायै, झकाराक्षरमातृकायै, ञानुरूपायै, ञिंनावासायै, ञकारेश्यै, ञणायुधायै, ञवर्णबीजभूषाढ्यायै, ञकाराक्षरमातृकायै, टङ्कायुधायै, टकाराढ्यायै, टोटाक्ष्यै, टसुकुन्तलायै, टङ्काश्रयायै, टलीरूपायै, टकाराक्षरमातृकायै, ठकुरायै, ठकुरेशान्यै, ठकारत्रितयेश्वर्यै, ठःस्वरूपायै, ठवर्णाढ्यायै, ठकाराक्षरमातृकायै, डकायै, डकेश्वर्यै, डिम्बायै, डवर्णाक्षरमातृकायै, ढिण्यै, ढेयायै, ढिल्लहस्तायै, ढकाराक्षरमातृकायै, णेशायै, णान्तायै, णवर्णात्मने, णवर्णाक्षरभूषणायै, तुंर्यै, तुर्यायै, तुलारूपायै, त्रिपुरायै, तामसप्रियायै, तोतुलायै, तारिण्यै, तारासप्तविंशतिरूपिण्यै, त्रिसुरायै, त्रिगुणिध्येयायै, त्र्यम्बकेश्यै, त्रिलोकधृते, त्रिवर्गेशायै, त्रय्यै, त्र्यक्षायै, त्रिपदायै, त्रेतरूपिण्यै, त्रिलोकजनन्यै, त्रेतायै, त्रिपुरेश्वरपूजितायै, त्रिकोणस्थायै, त्रिकोणेश्यै, त्रिकोणान्तर्निवासिन्यै, त्रिकोणपूजनतुष्टायै, त्रिकोणपूजनप्रियायै, वसुकोणस्थितायै, वश्यायै, वसुकोणार्थवादिन्यै, वसुकोणासनेसंस्थायै, षट्चक्रक्रमपूजितायै, नागपत्रस्थितायै, शार्यै, त्रिवृत्तपूजनार्थदायै, चतुर्द्वाराग्रगायै, च-

ऋब्राह्मान्तरनिवासिन्यै, तामस्यै, तुम्बुरुस्तुत्यायै, तोमरायुध-मण्डितायै, तुलाकोटिस्वनायै, ताप्यै, तेजोसि ॐतपसः फलदा-यिन्यैस्वाँहा ध्यानम् ॥ तयैं, तरणिरूपायै, तारकासुरघातिन्यै, तरलाक्ष्यै, तमोहर्त्र्यै, तकाराक्षरमातृकायै, स्थल्यै, स्थविररू-पायै, स्थूलायै, स्थाँल्यै, स्थलाब्जिन्यै, स्थविरेश्यै, स्थूलमुख्यै, थकाराक्षरमातृकायै, दूतिकायै, शिवदूत्यै, दण्डायुधधरायै, द्युतये, दीपायै, दीनानुकम्पाँयै, दम्भोलिधरवल्लभायै, देशा-नुचारिण्यै, द्रेक्कायै, द्राविडेश्यै, दवीयस्यै, दाक्षायण्यै, द्रुमल-तायै, देवमात्रे, आदिदेवतायै, दधिँजायै, दुर्लभादेव्यै, देव-तायै, परमाक्षरायै, दामोदरसुपूज्यायै, दामोदरवरप्रदायै, दण्डहस्तायै, दण्डिपूज्यायै, दकाराक्षरमातृकायै, धर्म्यायै, धर्ममूर्धन्याँयै, धनदायै, धनवर्धिन्यै, धृतये, धूर्तायै, धन्यवध्वै, धकाराक्षरमातृकायै, नलिन्यै, नलिनहस्तायै, नाराचायुध-धारिण्यै, नीपोपवनमध्यस्थाँयै, नगरेश्यै, नरोत्तमायै, नरेश्वर्यै, नृपाराध्यायै, नृपपूज्यायै, नृपार्थदायै, नृपसेव्यायै, नृपवन्द्यायै, नरनारायणप्रस्वै, नँर्तक्यै, नीरजाक्ष्यै, नवर्णाक्षरभूषणायै, पद्मेश्वर्यै, पद्ममुख्यै, पत्रियानायै, परापरायै, पारावतसुतायै, पेयायै, परवर्गविमर्दिन्यै, त्रिपुरारिवँध्वै, पम्पायै, पत्र्यै, पत्रीश-वाहनायै, पीवरांसायै, पतिप्राणायै, पीतलाक्ष्यै, पतिप्रियायै, पाठायै, पीठस्थितायै, पीतवस्त्रालङ्कारभूँषणायै, पुरूरवस्तुतायै, पात्र्यै, पुत्रिकायै, पुत्रदायै, प्रजायै, पुष्पोत्तमायै, पुष्पवत्यै, पुष्पमालाविभूषितायै, पुष्पमालाधिशोभाढ्यायै, पकाराक्षँरमा-तृकायै, फलदायै, स्फीतवस्त्रायै, फेरुरावविभूषणायै, फल्गुन्यै,

फल्गुतीर्थस्थायै, फवर्गकृतमण्डनायै, वलदायै, वालखिल्यायै, बालायै, तेजोसि बलरिपुप्रियायै ८०० ॥ ध्यानम् ॥ बाल्यावस्थायै, बन्धरेश्यै, बकाराकृतिमातृकायै, भद्रिकायै, भीमपत्न्यै, भीमायै, भर्गशिखायै, अभयायै, भयघ्न्यै, भीमनादायै, भयानकमुखेक्षणायै, भिल्लीश्वर्यै, भीतिहरायै, भद्रदायै, भाग्यवर्धिन्यै, भगमालायै, भगावासायै, भवान्यै, भवतारिण्यै, भंगयोनये, भगाकारायै, भगस्थायै, भगरूपिण्यै, भगलिङ्गामृतप्रीतायै, भकाराक्षरमातृकायै, मान्यायै, मानप्रदायै, मीनायै, मीनकेतनलालसायै, मदोद्धूतायै, मनोतीतायै, मेनायै, मैनाकवत्सलायै, मांसाहारायै, मांसप्रीतायै, मत्स्यघातायै, महत्तरायै, मेरुशृङ्गाग्रतुङ्गस्थायै, मोदकाहारपूजितायै, मातङ्गिन्यै, मदोन्मत्तायै, मदमत्ता मठेश्वर्यै, मज्ञायै, मुग्धाननायै, मुग्धायै, मकाराक्षरभूषणायै, यशस्विन्यै, यतीशान्यै, यत्नकर्त्र्यै, यजुःप्रियायै, यज्ञदात्र्यै, यज्ञफलायै, यजुर्वेदफलायै, यतये, यशोदायै, यतिसेव्यायै, यात्रायै, यात्रिकवत्सलायै, योगीश्वर्यै, योगगम्यायै, योगीन्द्रजनवत्सलायै, यदुपुत्र्यै, यमघ्न्यै, यकाराक्षरमातृकायै, रत्नेश्वर्यै, रमानाथसेव्यायै, रथ्यायै, रजस्वलायै, राज्यदायै, राजराजेश्यै, रोगहर्त्र्यै, रजोवत्यै, रत्नाकरसुतायै, रम्यायै, रात्र्यै, रात्रीपतिप्रभायै, रक्षोघ्न्यै, राक्षसेशान्यै, रक्षोनाथसमर्चितायै, रतिप्रियायै, रतिसुखायै, रक्तारक्तशेखरायै, लम्बोदर्यै, ललज्जिह्वायै, लास्यतत्परमानसायै, लूतातन्तुवितानास्यायै, लक्ष्म्यै, लज्जालयायै, अंलिन्यै, लोकेश्वर्यै, लोकदात्र्यै, लाटस्थायै, लक्ष्मणाकृतये, लम्बायै, लम्बकुचोल्लासायै, लकाराक्षरवर्धिन्यै, लिङ्गप्रीतायै, कलिङ्गेश्यै,

तेजोसि ॐलिङ्गस्थायैस्वांह्रीं ध्यानम् ॥ लिङ्गलिङ्गिन्यै, लक्ष्मी
रूपायै, रसोल्लासायै, रामायै, रेवायै, रजोवत्यै, लयदात्र्यै
लक्ष्मणायै, लोलायै, लकाराक्षरमातृकायै, वाराह्यै, वरदात्र्यै
वीरस्वै, वरदायिन्यै, वीरेश्वर्यै, वीरजन्यायै, वरचर्वणचर्चि
तायै, वरायुधायै, वराकायै, वामनायै, वामनाकृतये, वधूतायै
वधकावध्यायै, वध्यभुवे, वणिजप्रियायै, वसन्तलक्ष्म्यै, व
टुक्यै, वटुकायै, वटुकेश्वर्यै, वटुप्रियायै, वामनेत्रायै, वामाचार
कलालसायै, वात्यायै, वाम्यायै, वरारोहायै, वेदमात्रे, वसु
न्धरायै, वयोयानायै, वयस्यायै, वकाराक्षरमातृकायै, शम्भुप्रि
यायै, शरच्चर्चायै, शाद्वलायै, शशिवत्सलायै, शीतद्युतये, शी
तरसायै, शोणोष्ठ्यै, शीकरप्रभायै, श्रीवत्सलाञ्छनायै, शर्वायै,
शर्ववामाङ्गवासिन्यै, शशाङ्कामलशोभाढ्यायै, शार्दूलतनवे,
अद्रिजायै, शेषहर्त्र्यै, शमीमूलायै, शकारकृतशेखरायै, षोड
शाक्षरमन्त्रेश्यै, षाढायै, षोडांयै, षडाननायै, षट्कूटायै, षड्सा
स्वादायै, षडशीतिमुखाम्बुजायै, षडास्यजनन्यै, षण्ठायै, षव
र्णाक्षरमातृकायै, सरस्वतीप्रस्वै, सर्वायै, सर्वगायै, सर्वतोमु
खायै, समायै, सीमायै, सतीमात्रे, सागराभयदायिन्यै, सम
स्तपापशमन्यै, सालभञ्ज्यै, सुदक्षिणायै, सुषुम्यै, संरसायै,
साध्व्यै, सामगायै, सामवेदजायै, सत्यप्रियायै, सोममुख्यै,
सूत्रस्थायै, सूतवल्लभायै, सनकेश्यै, सुनन्दायै, संवर्णायै, स्वा
स्थ्यदायिन्यै, हाहाहूहूस्वरूपायै, हलदात्र्यै, हलिप्रियायै, हंस
स्वरूपानुगतायै, सर्वमातृकपूजितायै, हरिदीश्वरपूज्यात्मने, ह
विष्याहुतिवल्लभायै, ॐ ऐंसौःह्रींमहाविद्यायै, तेजोसि आंशां

ह्रांहूंस्वरूपिण्यैस्वांहों ॥ पुण्यं पुण्यजनस्तुत्यं ज्ञुत्यं वैष्णवसंमितम्। इदं यः पठते देवि श्रावयेद्वा शृणोति च। स एव भगवान्देवः सत्यं सत्यं महेश्वरि। एककालं द्विकालं वा त्रिकालं पठते नरः। वामाचारपरो देवि तस्य पुण्यफलं शृणु। मूकत्वं वधिरत्वं च कुष्टं हन्याच्च श्वित्रिकाम्। वातपित्तकफान् गुल्मान्रक्तस्रावं विषूचिकाम्। सद्यः शमयते देवी श्रद्धया यः पठेन्निशि। अपस्मारं कर्णपीडां शूलं रौद्रभगन्दरम्। मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम्। भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि। सद्यस्तस्य महेशानी शारिका वरदा भवेत्। चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिवृत्तये। दत्त्वा बलिं सुरां क्षौद्रं समत्स्यमांसभक्तकम्। वर्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविष्यति। यः पठेद्देवि लोलायां चितायां शवसन्निधौ। पाठमात्रं त्रिवारं तु तस्य पुण्यफलं शृणु। ब्रह्महत्यां गुरोर्हत्यां सुरापानं तु गोवधम्। महापातकसङ्घातं पातकं चोपपातकम्। स्तेयं च हेमहारित्वोद्भवं पापं हि नाशयेत्। स एव हि रमापुत्रो यशस्वी लोकपूजितः। वरदानक्षमो देवि वीरेशो भूतवत्सलः। चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ। त्रिकालं श्रद्धया युक्तः स भवेद्भैरवेश्वरः। किं किं न लभते देवि साधको धीरसाधकः। पुत्रवान्धनवांल्लोके सत्याचारपरः शिवः। शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रवरं शुभम्। इहलोके सुखीभूत्वा परत्र च दिवं व्रजेत्। इति नामसहस्रं तु शारिकाया मनोरमम्। गोप्यं गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ इति श्रीशारिकादेव्याः सहस्रनामस्तोत्रम् ॥

ॐ श्रीगणेशसहस्रनामावली ॥

भैरवः ॥ देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नगणाकुलः । मनसा स विनिर्माय ततस्तु विघ्नकारकम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि । विघ्नप्रशमनोपायं पप्रच्छ च परिश्रमम् । सन्तर्प्य पूजया शम्भोर्महागणपतिः स्वयम् । सर्वविघ्नप्रशमनं सर्वाश्रमफलप्रदम् । नमस्तस्मै स्वनाम्नैव सहस्रमिदमब्रवीत् ॥ अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमन्त्रस्य, महागणपतिर्ऋषिः, गणेशो देवता, नानाविधानि छन्दांसि, हुमितिबीजं, ॐमितिशक्तिः, स्वाहा इति कीलकं, आत्मनो०—श्रीमहागणपतिप्रसादसिद्ध्यर्थे सर्वविघ्ननिवारणार्थं पाठे होमे वा विनियोगः ॥ गां, गीं, गूं, गैं, गौं, गः, इतिन्यासः। प्राणायामः ॥ ध्यानं ॥ जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलेर्बन्धने स्रष्टुं वारिरुहोद्भवेन विधिना शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथने सिद्धाधिपैर्मुक्तये ध्यातः पञ्चशरेण लोकविजये पायान्स नागाननः ॥ ॐ गं तत्पुरुषायविद्महे, वक्रतुण्डाय धीमहि, तन्नो दन्ती प्रचोदयात् ३ ॥ श्रीगणेशः ॥ ॐ गणेश्वराय स्वाहा, गणक्रीडाय, गणनाथाय, गणाधिपाय, एकदन्ताय, वक्रतुण्डाय, गजवक्त्राय, महोदराय, लम्बोदराय, धूम्रवर्णाय, विकटाय, विघ्ननाशकाय, सुमुखाय, दुर्मुखाय, बुद्धाय, विघ्नेशाय, अघविनाशनाय, भीमाय, प्रमोदाय, आनन्दाय, सुरानन्दाय, मदोत्कटाय, हेरम्बाय, शम्बराय, शम्भवे, लम्बकर्णाय, महाबलाय, नन्दनाय, लुम्पटाय, भीममेघनादाय, धनञ्जयाय, विनायकाय, विरूपाक्षाय, वीराय, शूरवरप्रदाय, महागण-

पतये, बुद्धिप्रियाय, क्षिप्रप्रसादनाय, रुद्रप्रियाय, गणाध्यं-क्षाय, उमापुत्राय, गजाननाय, कुमारगुरवे, ईशानपुत्राय, मूषकवाहनाय, सिद्धिप्रदाय, सिद्धपतये, सिद्धाय, सिद्धिविना-यकाय, अविघ्नतुम्बुरवे, सिंहवाहनाय, मोहिनीप्रियाय, कटङ्क-टाय, राजपुत्राय, सालङ्कटाय, सिताय, अमिताय, कूष्मा-ण्डाय, सामसम्भूताय, दुर्जयाय, धूर्जयाय, नयाय, भूपतये, भुवनेशानाय, भूतानांपतये, अव्ययाय, विश्वकर्त्रे, विश्व-मुखाय, विश्वरूपाय, अतिनिर्गुणायँ, कवये, कवीनामृषभाय, ब्राह्मणाय, ब्रह्मवित्पतये, ज्येष्ठराजाय, श्रीनिधये, श्रीपतये, नि-धिप्रियाय, हिरण्मयपुरान्तःस्थाय, सूर्यमण्डलमध्यंगाय, कराह-तिध्वस्तसिन्धुसलिलाय, पुष्पदन्तभिदे, उमाङ्ककेलिसम्भूताय, मुक्तिदाय, फलदायकाय, किरीटिने, कुण्डलिने, हारिणे, वनमालिने, मनोमयायँ, वैमुख्यहतदैत्यश्रिये, पादगत्याजित-क्षितये, सद्योजाताय, स्वर्णकुञ्जमेखलिने, दुर्निमित्तहृते, दुःस्व-प्नहृते, प्रहसनाय, गुणिने, नादप्रतिष्ठिताय, तेजोसि ॐ स्वरू-पायस्वाँहाँ। ध्यानं ॥ ॐ सर्वरत्नाढ्यविलसन्नूपुराय, यूने, पीता-म्बराय, खड्गधराय, खण्डवैशाखसंस्थिताय, चित्राङ्गाय, श्याम-दशनाय, भालचन्द्राय, हविर्भुजाय, योगाधिपायँ, तारकस्थाय, पुरुषाय, गजकर्णकाय, गणाधिराजाय, विजयस्थिराय, गज-पतये, ध्वजिने, देवदेवाय, स्मरत्राणदीपकाय, वायुँकीलकाय, विपश्चिद्वरदाय, नादाय, नादभिन्नमहारवाय, वराहवदनाय, मृत्युञ्जयाय, व्याघ्राजिनाम्बराय, इच्छाशक्तिभवाय, देवत्रात्रे, दैत्यविमर्दनाय, शम्भुवक्त्रोद्भवाय, शम्भुकोपजाय, शम्भु-

हास्यभुवे, शम्भुतेजसे, शिवाशोकहारिणे, गौरीसुखावहाय उमाङ्गमलजाय, गौरीतेजोभुवे, स्वर्धुनीभवाय, मर्त्यकायाय महानादायँ, गिरिवर्ष्मणे, शुभाननाय, सर्वात्मने, सर्वदेवा त्मने, ब्रह्ममूर्ध्ने, ककुत्पतये, ब्रह्माण्डकुम्भजिते, व्योमभालाय सत्यशिरोरुहाय, जगज्जन्मलयोन्मेषनिमेषाँय, अग्न्यर्कसोमदृशे गिरीन्द्रवदनाय, धर्माय, धर्मिष्ठाय, सामबृंहिताय, ग्रहर्क्षदर्श नाय, वाणीजिह्वाय, वासुकिनासिकाय, भ्रूमध्यसंस्थितब्रह्मणे, ब्रह्मविद्यांमदोदकाय, कुलाचलांसाय, सोमार्कघण्टाय, रुद्र शिरोधराय, नदीनदभुजाय, सर्पाङ्गुलीकाय, तारकैर्नखाय निम्ननाभये, श्रीहृदयाय, मेरुपृष्ठाय, अर्णवोदराँय, कुक्षिस्थय क्षगन्धर्वरक्षःकिन्नरमानुषाय, पृथ्वीकटये, सृष्टिलिङ्गाय शैलोरवे, ह्रस्वजानुकाय, पातालजङ्घाय, मुनिपादे, कालाङ्गु ष्ठाय, त्रयीतनवे, ज्योतिर्मण्डलर्लांङ्गूलाय, हृदयालाननिश्चलाय हृत्पद्मकर्णिकस्थाय, वियत्केलिसरोवराय, सद्भक्तध्याननिग डाय, पूजावारिनिवारिताय, प्रतापिने, कश्यपाय, यत्नाय, गणकाय, मन्दराँय, बलिने, यशस्विने, धार्मिकाय, नेत्रे प्रमथाय, प्रमथेश्वराय, चिन्तामणिस्थलपतये, कल्पद्रुमवनाल याय, रत्नमण्डपमध्यस्थाय, तेजोसि ॐ रत्नसिंहासनाश्रयाय स्वाँहां ॥ ध्यानं ॥ तीव्रशिरोद्धृतपदाय, ज्वालिनीमौलिलालिताय नादनन्दितपीठश्रिये, भोगदाय, भूषिताननाय, प्रकामदायि नांपीठाय, स्फुरदुग्रासनाश्रयाय, तेजोवतांशिरोरत्नाय, सत्य नित्यावतंसिताय, सर्वविघ्नविनाशाँय, सर्वशक्त्यम्बुजालयाय रक्तपद्मासनाधाराय, वह्निधामत्रयालयाय, उन्नतप्रपदाय, गूढ

गुल्फाय, संवृत्तपार्ष्णिकाय, पीनजङ्घाय, श्लिष्टजानवे, स्थूलोरवे, प्रोन्नमत्कटये, निम्ननाभये, स्थूलकुक्षये, पीनवक्षसे, बृहद्भुजाय, पीनग्रीवाय, कम्बुकण्ठाय, लम्बोष्ठाय, लम्बनासिकाय, भग्नवामरदाय, तुङ्गसव्यदन्ताय, महाहनवे, ह्रस्वनेत्रत्रयाय, शूर्पकर्णाय, निबिडमस्तकाय, स्तबकाकारपाणये, रत्नमौलये, निरङ्कुशाय, सर्पहारकटिसूत्राय, सर्पयज्ञोपवीतभृते, सर्पकोटीरकटकाय, सर्पग्रैवेयकाङ्गदाय, सर्पकक्ष्योदरबन्धाय, सर्पराजोत्तरच्छदाय, रक्ताय, रक्ताम्बरधराय, रक्तमाल्यविभूषणाय, रक्तेक्षणाय, रक्तकराय, नित्यरक्तोष्ठपल्लवाय, श्वेताय, श्वेताम्बरधराय, श्वेतमाल्यविभूषणाय, श्वेतातपत्ररुचिराय, श्वेतचामरवीजिताय, सर्वावयवसम्पूर्णाय, सर्वलक्षणलक्षिताय, सर्वभूषणभूषाढ्याय, सर्वशोभासमन्विताय, सर्वमङ्गलमङ्गल्याय, सर्वकारणकारणाय, सर्वदेवकराय, शार्ङ्गिणे, बीजपूरिणे, गदाधराय, शुभाङ्गाय, लोकशुभदाय, सुतन्तवे, तन्तुवर्धनाय, इक्षुचापधराय, शूलिने, चक्रपाणये, सरोजभृते, पाशिने, धृतोत्पलभराय, मञ्जरीभृते, सुदन्तभृते, कल्पवल्लीधराय, विश्वाभयदैककराय, वशिने, अक्षमालाधराय, ज्ञानमुद्रावते, मुद्गरायुधाय, पूर्णपात्रिणे, कम्बुधराय, विधृतालसमोदकाय, करस्थाम्रफलाय, चूतकलिकाभृते, कुठारभृते, पुष्करस्थस्वर्णघटाय, पूर्णरत्नाभिवर्षकाय, भारतीसुन्दरीनाथाय, विनायकरतिप्रियाय, महालक्ष्मीप्रियतमाय, सिद्धलक्ष्मीमनोरमाय, रमारमेशपूर्वाङ्गाय, उमोमेश्वरदक्षिणाय, महीवराहवामाङ्गाय, रतिकन्दर्पपश्चिमाय, आमोदमोदजननाय, तेजोसि ॐ स्वप्रमो-

दप्रमोदनाय स्वाहा ॥ ध्यानं ॥ समर्द्धितसमृद्धिश्रिये, ऋद्धिसिद्धिप्रवर्धनाय, दन्तसौमुख्यसुमुखाय, कान्तिकन्दलिताश्रयाय, मदनोपाश्रिताङ्घ्रये, कृतसौमुख्यदुर्मुखाय, विघ्नसोपप्लवोपघ्नाय, सर्वोन्नतमदद्रवाय, विघ्नहृते, निम्नचरणाय, द्राविणीशक्तिसत्कृताय, तीव्रप्रसन्नवदनाय, पालिनीपालितैकदृशे, मोहिनीमोहिताय, भोगदायिने, कान्तिमण्डिताय, कामिनीकान्तवक्त्रश्रिये, तीक्ष्णदृष्टये, एकदृशे, वसुधारामदाय, अनादाय, महाशङ्खनिधिप्रभवे, नमद्वसुमतीमौलिप्रद्धपद्मनिधिप्रभवे, सदासद्गुरुसंसेव्याय, रोचिष्केशहृदाश्रयाय, ईशानमूर्ध्ने, दैत्येन्द्रशिखापवनदंशनाय, प्रत्यग्रनयनाय, दिव्याय, दिव्यास्त्रशतहस्तधृते, ऐरावतादिसर्वाशावारणवारणप्रियाय, वज्राद्यस्त्रपरीवाराय, गणचण्डसमाश्रयाय, जयाजयपरीवाराय, विजयाय, विजयाह्वयाय, विजयार्चितपादाब्जाय, नित्यानित्यावतंसिताय, विलासिनीकृतोल्लासाय, शुण्डिने, सौन्दर्यमण्डिताय, अनन्ताय, अनन्तसुखदाय, सुमङ्गलातिमङ्गलाय, ज्ञानाश्रयाय, क्रियाधाराय, इच्छाशक्तिनिषेविताय, सुभगासंश्रितपदाय, ललिताललिताश्रयाय, कामिनीपालकाय, कामाय, कामिनीकेलिलालिताय, सरस्वत्याश्रिताय, गौरीनन्दनाय, श्रीनिकेतनाय, गुरुगतिप्रदाय, वाचांसिंहाय, वागीश्वरीपतये, नलिनीकामुकाय, वामारामाय, ज्येष्ठामनोरमाय, रौद्रीमुद्रितपादाब्जाय, हुंबीजोत्तुङ्गशक्तिकाय, विश्वादिबीजस्वप्राणाय, स्वाहाशक्तिसकीलकाय, अमृताब्धिकृतावासाय, मदाघूर्णितलोचनाय, उच्छिष्टोच्छिष्टगणकाय, गणेशाय, गणनायकाय, सार्व-

कालिकसंसिद्धये, नित्यशोतिदिगम्बराय, अनपायाय, अनन्तदृष्टये, अप्रमेयाय, अजराय, अमराय, अनाविलाय, अप्रतिहताय, अच्युताय, अमर्त्याय, अक्षराय, अप्रतर्क्यजयाय, जाप्याय, अनाधाराय, अनामयाय, अमलाय, अगाधसिद्धये, अद्वैताय, अघोराय, अप्रमिताननाय, अनाकाराय, अधिरूपाय, अग्निवलघ्नाय, अव्यक्तलक्षणाय, आधारपीठाय, आधाराय, आधाराधेयवर्जिताय, आखुकेतनाय, तेजोसि ॐ आशापूरकाय, ॥ ध्यानं ॥ आखुवाद्यवाहनाय, इक्षुसागरमध्यस्थाय, इक्षुभक्षणलालसाय, इन्द्रचापातिरिक्तश्रिये, इक्षुचापनिषेविताय, इन्द्रगोपसमानश्रिये, इन्द्रनीलनिभद्युतये, इन्दीवरदलश्यामाय, इन्दुमण्डलनिर्मलाय, इध्मप्रियाय, इळाधाम्ने, इळावते, इन्दिराप्रदाय, इक्ष्वाकुविघ्नविध्वंसिने, इतिकर्तव्यतारताय, ईशानमौलये, ईशानाय, ईशानप्रियाय, ईतिघ्ने, ईषणात्रयकल्पान्ताय, ईहामात्रविवर्जिताय, उपेन्द्राय, उग्राय, उडुभृन्मौलये, ईरुण्डकप्रियाय, उन्नताननाय, उत्तुङ्गाय, उदाराय, त्रिदशाग्रण्ये, ऊर्जस्वते, उज्ज्वलात्मीयाय, ऊहापोहदुरासदाय, ऋग्यजुस्सामनयनाय, ऋद्धिसिद्धिसमर्पकाय, ऋजुस्वान्तैकसुलभाय, ऋणत्रयविमोचकाय, स्वभक्तानांलुप्तविघ्नाय, सुरद्विषां लुप्तशक्तये, विमुखार्चनांलुप्तश्रिये, लूताविस्फोटनाशनाय, एकारपीठमध्यस्थाय, एणपादकृतोदराय, एजिताखिलदैत्यश्रिये, एधिताखिलसंश्रयाय, ऐश्वर्यनिधये, ऐहिकामुष्मिकैश्वर्यप्रदाय, ऐरम्मदसमुन्मेषाय, ऐरावतसमाननाय, ओङ्कारवाच्याय, ॐकाराय, ओजस्वते, औषधीपतये, औदार्यनिधये,

औद्धत्यधुर्याय, औन्नत्यनिःसमाय, सर्वनागानामङ्कुशाय, अङ्कुशाकारसंस्थिताय, असमस्तविसर्गान्तपदेषुपरिनिष्ठिताय, कमण्डलुधराय, कल्पाँय, कपर्दिने, कलभाननाय, कर्मसाक्षिणे, कर्मभोक्त्रे, कर्माकर्मफलप्रदाय, कदम्बगोलकाकाराय, कूष्माण्डगणनायकाय, कारुण्यदेहाय, कपिलाय, कथकाँय, कटिसूत्रभृते, खर्वाय, खड्गप्रियाय, खड्गिने, खेयान्तःस्थाय, खनिर्मलाय, खट्वाङ्गशृङ्गनिलयाय, खट्वाङ्गिने, षड्गुणाश्रयाय, गुणाढ्याँय, गहनाय, गेयाय, गद्यपद्यसुधार्णवाय, गद्यगानप्रियाय, गर्जाय, गीतगीर्वाणपूजिताय, गुह्याचाररताय, गुह्याय, गुह्यागमनिरूपिताय, गुह्याशयाँय, गुडाब्धिस्थाय, गुरुगम्याय, गुरोर्गुरवे, घण्टाघुर्घुरिकामालिने, घटकुम्भाय, घटोदराय, चण्डाय, चण्डेश्वराध्यक्षाय, चण्डीशाय, तेजोसि ॐचण्डविक्रमायस्वाँहा ॥ ध्यानं ॥ ॐचराचरपित्रेस्वाहा चिन्तामणये, चर्वणलालसाय, छन्दसे, छन्दोभवाय, छन्दोदुर्लक्ष्याय, छन्दविग्रहाय, जगद्योनये, जगत्साक्षिणे, जगदीशायँ, जगन्मयाय, जयाजयपराय, अजेय्याय, जितसिंहासनप्रभवे, ज्वलज्वलोल्लसद्दानझाङ्कारिभ्रमराकुलाय, टङ्कारस्फारसंरावाय, टङ्कारमणिनूपुराय, ठद्वयपल्लवान्ताय, सर्वमन्त्रेषुसिद्धिदाय, दिण्डिमुण्डाँय, डाकिनीशाय, डामराय, डिण्डिमप्रियाय, ढक्कानिनादमुदिताय, ढङ्काय, ढौण्ढिनायकाय, तत्त्वानांप्रकृतितत्त्वाय, तत्त्वंपदनिरूपिताय, तारकान्तरसंस्थाय, तारकाँय, तारकान्तकाय, स्थाणवे, स्थाणुप्रियाङ्गभुवे, स्थावरजङ्गमाधिपाय, दक्षयज्ञप्रमथनाय, दात्रे, दानमदोदयाय, दयावते,

दिव्यविभवाय, दण्डँभृते, दण्डनायकाय, दन्तप्रभिन्नाभ्रमालाय, दैत्यवारणदारणाय, दंष्ट्रालग्नद्विपघटाय, देवार्थोत्तगजाकृतये, धनाय, धनपतिबन्धवे, धनदाय, धरणीधराय, ध्यानैकप्रकँटाय, ध्येयाय, ध्यानाय, ध्यानपरायणाय, ध्वनिप्रकृतिधित्काराय, ब्रह्माण्डावलिमेखलाय, नन्दिने, नन्दिप्रियाय, नादाय, नादमध्यप्रतिष्ठिताय, निष्कँलाय, निर्मलाय, नित्याय, नित्यानित्याय, निरामयाय, परंव्योम्ने, परंधाम्ने, परमात्मने, परंपदाय, परात्पराय, पशुपँतये, पशुपाशविमोचनाय, पूर्णानन्दाय, परानन्दाय, पुराणपुरुषोत्तमाय, पद्मप्रसन्ननयनाय, प्रणताज्ञाननाशनाय, प्रमाणप्रत्ययातीताय, प्रणतार्तिनिवारणाय, फणिहस्ताय, फणिपंतिफूत्काराय, फाणितप्रियाय, बाणार्चिताङ्घ्रियुगलाय, बालकेलिकुतूहलाय, ब्रह्मणे, ब्रह्मार्चितपदाय, ब्रह्मचारिणे, बृहस्पतये, बृहत्तमाय, ब्रह्मपराय, ब्राह्मण्यँाय, ब्रह्मवित्प्रियाय, भ्रूक्षेपदत्तलक्ष्मीकाय, गर्भाय, गर्भभयापहाय, भगवते, भक्तिसुलभाय, भूतिदाय, भूतिभूषणाय, भव्याय, तेजोसि ॐभूतालयायस्वाँहँ। ॥ ध्यानं ॥

ॐ भोगदात्रे, भ्रूमध्यगोचराय, मन्त्राय, मन्त्रपतये, मन्त्रिणे, मदमत्ताय, मदाननाय, मेखलाधीश्वराय, मन्दगतये, दन्तिनिभेक्षणँाय, महाबलाय, महावीर्याय, महाप्राणाय, महाननाय, यज्ञाय, यज्ञपतये, यज्ञगोप्त्रे, यज्ञफलप्रदाय, यज्ञेश्वराय, यज्ञगर्भँयाय, यागसवे, याजकप्रियाय, रसाय, रसप्रियाय, रक्तरञ्जकाय, रावणार्चिताय, राधारक्षाकराय, रत्नगर्भाय, राज्यसुखप्रदाय, लक्षालक्षँप्रदाय, लक्ष्याय, लक्ष्यस्थाय, लड्डुकप्रियाय,

लाभप्रियाय, लास्यपराय, लाभकृते, लोकविश्रुताय, वरेण्याय, वह्निवदनाय, वन्द्याय, वेदान्तगोचराय, विश्वकर्त्रे, विश्वचक्षुषे, विधात्रे, विश्वतोमुखाय, वामदेवाय, विश्वजेत्रे, वज्रिणे, वज्रनिवारणाय, विश्वबन्धनविष्कम्भाधाराय, विश्वाधाराय, विश्वेश्वराय, विभवे, शास्त्रे, शाखाग्रनिलयाय, शरण्याय, शम्बरेश्वराय, शब्दब्रह्ममयाय, प्राणाय, शम्भवे, शक्तिगणेश्वराय, षड्‌ऋतुकुसुमस्रग्विने, षडाधाराय, षडक्षराय, संसारवैद्याय, सर्वज्ञाय, सर्वभेषजभेषजाय, सृष्टिस्थितिलयक्रीडाय, असुरकुञ्जरभेदनाय, सिन्दूरितमहाकुम्भाय, सदसद्व्यक्तिदायकाय, समुद्रमथनेसाक्षिणे, स्वसंवेद्याय, स्वदक्षिणाय, स्वतन्त्राय, सत्यसङ्कल्पाय, सामगानरताय, सुखिने, हंसाय, हस्तिने, पिशाचेशाय, हवनाय, हव्यकव्यभुजे, हव्याय, हुतप्रियाय, हृष्टाय, हृल्लेखमन्त्रमध्यगाय, क्षेत्राधिपाय, क्षमाभर्त्रे, क्षमापारपरायणाय, क्षिप्रक्षेमकराय, क्षेमानन्दाय, क्षोणीसुरद्रुमाय, धर्मप्रदाय, अर्थदाय, कामदात्रे, सौभाग्यवर्धनाय, विद्याप्रदाय, विभवदाय, तेजोसि ॐ भुक्तिमुक्तिफलप्रदायस्वाहा ॥ ध्यानं ॥ अतिरूपकराय, वीरश्रीप्रदाय, विजयप्रदाय, सर्ववश्यकराय, गर्भदोषघ्ने, पुत्रपौत्रदाय, मेधादाय, कीर्तिदाय, शोकहारिणे, दौर्भाग्यनाशनाय, प्रतिवादिमुखस्तम्भाय, दुष्टचित्तप्रसादनाय, पराभिचारश्रवणाय, दुःस्वप्नघ्नाय, बन्धमोक्षदाय, लवत्रुटिकलाकाष्ठानिमेषतत्पराय, क्षणाय, घटीमुहूर्तप्रहराय, दिवानक्ताय, अहर्निशाय, पक्षाय, मासाय, अयनाय, वर्षाय, युगाय, कल्पाय, महालयाय, राशितारातिथियोगवारार्क्षकरणांशकाय, लग्नहोराकाल-

चक्राय, मेरवे, सप्तर्षिभ्यः, ध्रुवाय, राहवे, मन्दाय, कवये, जीवाय, बुधाय, भौमाय, शशिने, रवये, कालशक्तये, स्थितये, विश्वस्मै, स्थावराय, जङ्गमाय, जगते, भुवे, अद्भ्यः, अग्नये, मरुते, व्योम्ने, अहङ्कृतये, प्रकृतये, पुंसे, ब्रह्मणे, विष्णवे, शिवाय, रुद्राय, ईशाय, शक्तये, सदाशिवाय, त्रिदशेभ्यः, पितृभ्यः, सिद्धेभ्यः, यक्षरक्षोभ्यः, किन्नरेभ्यः, सिद्धविद्याधरेभ्यः, भूतेभ्यः, मनुष्येभ्यः, पशुभ्यः, खगेभ्यः, समुद्रेभ्यः, सरिद्भ्यः, शैलेभ्यः, भूतभव्यभवोद्भवाय, सांख्यपातञ्जलयोगेभ्यः, पुराणश्रुतिस्मृतिभ्यः, वेदाङ्गेभ्यः, समाचाराय, मीमांसान्यायविस्तराय, आयुर्वेदाय, धनुर्वेदाय, गन्धर्वाय, काव्याय, नाटकाय, वैखानसाय, भागवताय, मानुष्याय, पाञ्चरात्रिकाय, शैवाय, पाशुपताय, कालीमुखाय, भैरवशासनाय, शाक्ताय, वैनायकाय, सौरजैनार्हसंहिताय, सते, विराजे, असते, तेजोसि ॐ व्यक्ताय स्वाहा ॥ ध्यानं ॥ ॐ अव्यक्ताय स्वाहा, सचेतनाय, अचेतनाय, बन्धकाय, मोक्षसुखदाय, भोगाय, योगाय, महते, अणवे, स्वस्तिहुंफट्स्वधास्वाहाश्रौषट्वौषट्वषण्मयाय, ज्ञानाय, विज्ञानाय, आनन्दाय, बोधाय, संविदे, समाय, शमाय, एकाय, एकाक्षराधाराय, एकाक्षरपरायणाय, एकाग्रधिये, एकवीराय, एकानेकस्वरूपधृषे, द्विरूपाय, द्विभुजाय, द्व्यक्षाय, द्विरदाय, द्विपरक्षकाय, द्वैमातुराय, द्विवदनाय, द्वन्द्वहीनाय, द्वयातिगाय, त्रिधामात्राकृतस्नेहाय, त्रिवर्गफलदायकाय, त्रिगुणात्मने, त्रिलोकादये, त्रिशक्त्यंशाय, त्रिलोचनाय, चतुर्बाहवे, चतुर्दन्ताय, चतुरात्मने, चतुर्मुखाय, चतुर्वर्गमयोपायाय, चतु-

वर्णाश्रमाश्रयाय, चतुर्वेदवचोवृत्तिपरिवृत्तिप्रवर्तकाय, चतुर्थीपूजनप्रीताय, चतुर्थीतिथिसम्भवाय, पञ्चाक्षराय, पञ्चात्मने, पञ्चास्याय, पञ्चकृत्यकृते, पञ्चधाराय, पञ्चवर्णाय, पञ्चाक्षरपरायणाय, पञ्चतालाय, पञ्चकराय, पञ्चप्रणवभाविताय, पञ्चब्रह्ममयस्फूर्तये, पञ्चावरणवारिताय, पञ्चभक्ष्यप्रियाय, पञ्चबाणाय, पञ्चशिवात्मकाय, षट्कोणपीठाय, षट्चक्रधाम्ने, षड्ग्रन्थिभेदकाय, षडङ्गध्वान्तविध्वंसिने, षडङ्गुलमहाह्रदाय, षण्मुखाय, षण्मुखभ्रात्रे, षड्शक्तिपरिवारिताय, षड्वर्गवैरिविध्वंसिने, षडूर्मिभयभञ्जनाय, षट्कर्मदूराय, षट्कर्मिणे, षाड्गुण्याय, षड्रसाश्रयाय, सप्तपातालचरणाय, सप्तद्वीपोरुमण्डलाय, सप्तस्वर्लोकमुकुटाय, सप्तसप्तिवरप्रदाय, सप्ताङ्गराज्यसुखदाय, सप्तर्षिगणवन्दिताय, सप्तच्छन्दोनिधये, सप्तहोत्रे, सप्तस्वराश्रयाय, सप्ताब्धिकेलिकासाराय, सप्तमातृनिषेविताय, सप्तच्छन्दमहामोदाय, सप्तच्छन्दसुखप्रभवे, अष्टमूर्तये, ध्येयमूर्तये, अष्टप्रकृतिकारणाय, अष्टाङ्गयोगफलभृते, अष्टपत्राम्बुजासनाय, अष्टशक्तिसमानश्रिये, अष्टैश्वर्यप्रदायकाय, अष्टपीठोपपीठश्रिये, अष्टमातृसमावृताय, अष्टभैरवसेव्याय, तेजोसि ॐअष्टवसुवन्द्यायस्वाहा ॥ ध्यानं ॥ ॐअष्टमूर्तिमतेस्वाहा, अष्टचक्रस्फुरन्मूर्तये, अष्टद्रव्यहविःप्रियाय, अष्टश्रिये, अष्टसामश्रिये, अष्टहृष्टसगीतकाय, नवनागासनाधेयाय, नवनिविडसेविताय, नवद्वारपुराधाराय, नवाधारनिकेतनाय, नवनारायणस्तुत्याय, नवदुर्गानिषेविताय, नवनाथमहानाथाय, नवनागविभूषणाय, नवरत्नविचित्राङ्गाय, नवशक्तिशरोद्यताय, दशात्मकाय, दशभु-

जाय, दशदिक्पतिवन्दिताय, दशध्येयाय, दशप्राणाय, दशेन्द्रियनियामकाय, दशाक्षरमहामन्त्राय, दशाशाव्यापिविग्रहाय, एकादशरुद्रस्तुत्याय, एकादशाक्षरैर्मनवे, द्वादशोद्दण्डदोर्दण्डाय, द्वादशान्तनिकेतनाय, त्रयोदशविधाभिन्नविश्वेदेवादिदैवताय, चतुर्दशेन्द्रवरदाय, चतुर्दशमनुप्रभवे, चतुर्दशाद्यविद्याढ्याय, चतुर्दशजगत्पतये, पञ्चदशसाम्ने, पञ्चदशशीतांशुनिर्मलाय, षोडशाधारनिलयाय, षोडशस्वरमातृकाय, षोडशान्तपदावासाय, षोडशेन्दुकलात्मकाय, सप्तदशीकलायै, सप्तदशाक्षराय, अष्टादशद्वीपपतये, अष्टादशपुराकृते, अष्टादशौषधीसृष्टये, अष्टादशविधिप्रभवे, अष्टादशलिपिकृतये, अष्टादशविजातिकृते, एकविंशपुंसे, एकविंशत्यङ्गुलिपल्लवाय, चतुर्विंशतितत्त्वात्मने, पञ्चविंशतिपूरुषाय, सप्तविंशतितारेशाय, सप्तविंशतियोगकृते, द्वात्रिंशद्भैरवाधीशाय, चतुस्त्रिंशन्महाह्रदाय, षड्त्रिंशत्तत्त्वसम्भूतये, अष्टात्रिंशत्कलात्मकाय, नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय, पञ्चाशदक्षरश्रेणये, पञ्चाशद्रुद्रविग्रहाय, पञ्चाशद्विष्णुशक्तीशाय, पञ्चाशन्मातृकालयाय, द्विपञ्चाशद्वपुश्रेणये, त्रिषष्ठ्यक्षरसंश्रयाय, चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दिताय, चतुःषष्ठ्यर्णनिर्णेताय, चतुःषष्टिकलानिधये, अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय, चतुर्णवतिमन्त्रात्मने, षण्णवत्यधिकप्रभवे, शतानन्दाय, शतधृतये, शतपत्रायतेक्षणाय, शतानेकाय, शतमुखाय, शतधारवरायुधाय, सहस्रपत्रनिलयाय, सहस्रफणिभूषणाय, सहस्रशीर्षायपुरुषाय, सहस्राक्षाय, सहस्रपादे, सहस्रनामसंस्तुत्याय, सहस्राक्षबला-

पहाय, दशसहस्रफणिभृते, फणिराजकृतासनाय, अष्टाशीति-सहस्रौघमहर्षिस्तोत्रपाठिताय, लक्ष्याधारप्रियाधाराय, लक्ष्याधारमनोलयाय, चतुर्लक्षजगत्प्रीताय, चतुर्लक्षप्रकाशकाय, कोटिसूर्यप्रतीकाशाय, कोटिचन्द्रांशुनिर्मलाय, शिवोद्भवाद्यष्टकोटिविनायकधुरन्धराय, सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये, त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय, चतुरशीतिलक्षात्मजीवदेहव्यवस्थितये, अनन्तनाम्ने, अनन्तश्रिये, अनन्ताय, तेजोसि ॐअनन्तसौख्यदायस्वाहा ॥ इति वैनायकस्येदं नाम्नां सहस्रमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः । करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् । आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः । मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता । सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता । सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् । ओजस्तेजः कुलं शीलं प्रतापं वीर्यमार्यता । ज्ञानं विज्ञानमास्तिक्यं धनं धान्यं भवेद्ध्रुवम् । शाकिनीडाकिनीरक्षोयक्षग्रहापहारकम् । साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । दुःस्वप्ननाशनं नित्यं स्वामिचित्तप्रसादनम् । सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयप्रदम् । गर्भरक्षाकरं सर्ववन्ध्यादोषनिवारकम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् । देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ॥ मनोरथप्रदं नित्यं सर्वरोगविनाशकम् । महागणपतेर्नाम्नां सहस्रं पठ्यते तु यः । सायं मध्यन्दिने प्रातस्तस्य सिद्धिर्भवेद्ध्रुवम् । इति श्रीगणपतिसहस्रनाम सम्पूर्णम् ॥

श्रीमहाराज्ञीस्तोत्रम् ।

ॐ श्रीभैरव उवाच। अधुना कथयिष्यामि स्तोत्रराजं परात्परम्। मूलमन्त्रमयं दिव्यं तत्त्वभूतं मनोहरम् ॥ राज्ञीप्रियं पापहरं लक्षपूजाफलप्रदम् । जपलक्षसमं स्तोत्रं ध्यानकोटिसमं प्रिये ॥ राज्ञीस्तोत्रस्य देवेशि ब्रह्मा ऋषिरुदाहृतः । गायत्री छन्द इत्युक्तं श्रीराज्ञी देवतेरिता ॥ माया बीजं परा शक्तिः कामः कीलकमीश्वरि। भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥ ॥ अस्य श्रीमहाराज्ञीस्तवराजस्य श्रीब्रह्माऋषिः। गायत्री छन्दः, श्रीमहाराज्ञी भूतेश्वरी देवता, ह्रीं बीजं, सौः शक्तिः, क्लींकीलकं, आत्मनो० श्रीमहाराज्ञीप्रसादद्वारा भोगापवर्गसिद्ध्यर्थे, पाठे विनियोगः ॥ ध्यानम् ॥ उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां सिंहासनोपरिगतामुरगोपवीताम्। खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीं भजामि विकसद्वदनारविन्दाम् ॥ ॥ तारमिन्दुकलिकावतंसितं वेदसागरमणिं मनोहरम् । यो जपेदुषसि रत्नमालया राज्यमाशु लभते स साधकः ॥ १ ॥ भूतिमिन्दुनवबिम्बमण्डितां नादबिन्दुललितां जपेत्तु यः । वारमेकमुरुवारणस्थितो जेष्यति समयमयाऽरीन्रणे ॥ २ ॥ रसां जपेद्यो भुवनेशि मन्त्री त्वन्मन्त्रमध्ये मदनोपतप्तः । रम्भां समालिङ्ग्य विमानचारी लीलां भजेन्नन्दनवाटिकायाम् ॥ ३ ॥ वह्निबीजमणिमाद्यसिद्धिदं बिन्दुबिम्बशशिखण्डमण्डितम् । यो जपेन्निशि धनाभिलाषवान् स क्षणाद्भवति वित्तदोपमः ॥ ४ ॥ कामराजममराभिवन्दितं यो जपेन्निधुवनेऽक्षमालया । तस्य यान्ति वशतां सुराङ्गनाः किं पुनर्जगति भूभृदङ्गनाः ॥ ५ ॥ शक्तिं भक्त्या यो जपेच्छक्तिपूजाकाले कालीपादपद्मार्पितान्तः । नक्तं तस्य स्मेरवक्त्रा

घृताची वश्या वेश्या स्वर्गता वा शची च ॥ ६ ॥ भगवत्यै तथा राज्यै नाममन्त्रमिति स्मरेत् । यो देवि तस्य वश्याः स्युर्भैरवस्याष्टसिद्धयः ॥ ७ ॥ मायां नमोन्ते यदि साधकेन्द्रो जपेन्महेशानि शिवालयस्थः । तत्रैव देवीं परमार्थराज्ञीं पश्येत्स सद्यो वरसिद्धिदात्रीम् ॥ ८ ॥ ठद्वयं यदि जपेन्निशाक्षगे क्षीरभुक् स्वतटिनीतटस्थितः । जिष्णुविष्णुकमलासनेश्वरा यान्ति देवि वशतां तदा क्षणात् ॥ ९ ॥ भूगेहवृत्तत्रयनागपत्रषडारयोन्यश्रकबिन्दुबिम्बे । निषेदुषीं राजकुलाधिदेवीं राज्ञीं भजे राजकलावतंसाम् ॥ १० ॥ देवि श्रीभूतधात्रीप्रवरगुणमये निष्कले निर्गुणे मे माये मातः शरण्ये गिरिवरतनये चिन्मये तत्त्वरूपे । दुर्गे चण्डि प्रमाथे त्रिपुरविजयिनि स्मेरवक्त्रे वरेण्ये कारुण्याढ्ये प्रशस्ते सुरदितिजनुते राज्ञि वै त्वं प्रसीद ॥ ११ ॥ इति स्तोत्रं मन्त्रस्फुरणकरुणानन्दनिलयं पठेद्भक्त्या प्रातस्तव गिरिसुते योगनिलयम् । भवेत्सद्यो भूमौ नृपमुकुटनीराजितपदोऽमृतो मुक्तिं चान्ते तव भवनमाप्नोति वरदे ॥ १२ ॥ इति राज्याः परं तत्त्वं पञ्चाङ्गमखिलं शिवे । सर्वस्वं च रहस्यं च सर्वसारस्वतप्रदम् ॥१३॥ आनन्दवर्धनं गुह्यं परमैश्वर्यकारणम् । भोगापवर्गदं पुण्यं दारिद्र्यभयनाशनम् ॥१४॥ राज्यप्रदं भक्तिकरं सर्वशत्रुनिबर्हणम् । पञ्चाङ्गमखिलं देव्या न वक्तव्यं दुरात्मने ॥ तव भक्त्या मया ख्यातं गोपनीयं प्रयत्नतः ॥ १५ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञीस्तवराजः ॥

श्रीराज्ञीस्तुतिः ।

ॐ संसारसागरमहं तरितुं सुनौकां राज्ञीं नमामि शिरसा शिवसुन्दरीं त्वाम् ॥ सर्वेश्वरीं सकललोकसुखप्रदात्रीं त्वामेव

देवि सततं शरणं प्रपद्ये ॥ १ ॥ मातः पयोधरयुगं पिबतु त्वदीयं नागाननर्तुमुखवत्सलपुत्रयुग्मम् ॥ निर्णेजनाम्बुन इह स्पृहयाम्यहं तु त्वत्पादपद्मयुगलस्य भवाग्निशान्त्यै ॥ २ ॥ मातस्त्वदीयपरितोषविशेषलब्धे छत्रे प्रहृष्यतु सदा भगवान्सुरेन्द्रः ॥ पीयूषवर्षणकरात्तव देवि पादच्छत्राद्विना किमपि राज्ञि न नाम याचे ॥ ३ ॥ मोहाटवीविकटसंकटपीडितोऽहं राज्ञी प्रपन्नपरमार्तिहरा त्वमेका ॥ जाज्वल्यतेऽम्ब हृदयार्तिकरो ममान्तः पापाग्निरेशि शमयैनममास्वरूपे ॥ ४ ॥ आरारटीमि करुणं भवतापतप्तः प्रोल्लालपीमि पतितो भवदुःखसिन्धौ ॥ मोमोर्मि राज्ञि लुठितो भवसर्पदष्टस्त्वामन्तरेण शरणं मम कः शरण्ये ॥ ५ ॥ राज्ञि प्रपन्नवरदे सुकृतादपर्णां त्वामाश्रितोऽस्मि सुचिरात्तु महद्विचित्रम् ॥ किं नास्मि भैरवि ऋणैस्त्रिविधैर्विमुक्तः पाशैरिवोत्कटविषाक्तभुजङ्गमानाम् ॥ ६ ॥ राज्ञि प्रसीद नतसौख्यकरे मृडानि रुद्राणि रोगहरणे चतुरे प्रसीद ॥ शर्वाणि सर्वजनपापहरे प्रसीद गौरि प्रसीद गुणगौरि शिवे प्रसीद ॥ ७ ॥ कल्याणि राज्ञि जगदीश्वरि विश्वमातस्त्वामन्तरेण नहि देवि सुखं जनस्य ॥ पुत्रस्य दुःखहरणे सततोद्यता द्राक् मातैव हि स्तुतकुचा नु भवत्यवश्यम् ॥ ८ ॥ राज्यष्टकमिदं पुण्यं यः पठेद्धर्षपूरितः ॥ सोऽत्र द्राक् प्राप्नुयात्कामान्परलोके च स्वर्गतिम् ॥ ९ ॥ इति श्रीराज्ञीस्तुतिः ॥

श्रीज्वालामुखीस्तोत्रम् ।

ॐ जाज्वल्यमानवपुषा दशदिग्विभागान्सन्दीपयन्त्यभयपद्मगदावराढ्या ॥ सिंहस्थिता शशिकलाभरणा त्रिनेत्रा ज्वालामुखी हरतु मोहतमः सदा नः ॥ १ ॥ आब्रह्मकीटजननीं

महिषीं शिवस्य मुग्धस्मितां प्रलयकोटिरविप्रकाशाम् ॥ ज्वा-
लामुखीं कनककुण्डलशोभितांसां वन्दे पुनः पुनरपीह सहस्र-
कृत्वः ॥ २ ॥ देदीप्यमानमुकुटद्युतिभिश्च देवैर्दासैरिव द्विगुणि-
तांघ्रिनखप्रदीप्तिम् ॥ ज्वालामुखीं सकलमङ्गलमङ्गलां तामम्बां
नतोऽस्म्यखिलदुःखविपत्तिदग्ध्रीम् ॥ ३ ॥ क्षित्यब्हुताशप-
वनाम्बरसूर्यचन्द्रयष्ट्राख्यमूर्तिममलानपि पावयन्तीम् ॥ ज्वा-
लामुखीं प्रणतकल्पलतां शिवस्य साम्राज्यशक्तिमतुलां महतीं
नमामि ॥ ४ ॥ नौमीश्वरीं त्रिजगतोऽभयदानशौण्डां ज्वालाम-
हार्यभवजालहरां नमामि ॥ मोहान्धकारहरणे विमलेन्दुकान्ति
देवीं सदा भगवतीं मनसा स्मरामि ॥ ५ ॥ दुष्कर्मवायुभिरित-
स्तत एव दीप्तैः पापज्वलज्ज्वलनजातशिखाकलापैः ॥ दग्धं च
जीवयतु मां परितो लुठन्तं देवी दयार्द्रहृदयामृतपूर्णदृष्ट्या ॥६॥
ज्वालामुखी ज्वलदनल्पलयाग्निकोटिरोचिष्मती रविशशिप्रति-
भानकर्त्री ॥ भक्तस्य भर्गवपुषा भवभर्जनाय भूयात्सदाभ्युद-
यदानवदान्यमुख्या ॥ ७ ॥ त्वं चौषधीशमुकुटाऽहमसाध्य-
रोगस्त्वं चित्प्रदीप्तिरहमत्र भवान्धमग्नः ॥ त्वं चाम्ब ! कल्प-
तरुरेवमहं च भिक्षुर्ज्वालामुखि प्रकुरु देवि यथोचितं मे ॥८॥
यद्ध्यानकेसरिसमाक्रमणोत्थभीतेर्मर्मव्यथाजनकदुःखशतानि
सद्यः ॥ गोमायवन्ति परितो भृशकान्दिशीकानस्मांश्च पालयतु
सैव भवाब्धिदुःखात् ॥ ९ ॥ ज्वालामुखि क्षणमपीह विलम्ब-
मम्ब नार्तो ह्यनर्थपतितः सहते विपन्नः ॥ हस्तस्थितामृतकम-
ण्डलुधारिणैव मां मूर्च्छितं झटिति जीवय तापतप्तम् ॥ १० ॥
बाह्यान्ध्यनाशनविधौ रविचन्द्रवह्निज्योतींषि देवि दययाऽज-
नयः पुरा त्वम् ॥ एतत्तु रूपमखिलान्तरमोहरात्रिध्वान्ता-

न्तकारि तव यत्स्फुरतादतोऽन्तः ॥ ११ ॥ मन्ये त्रिधामनयने नयनत्रयं ते भक्तार्तिनाशननिमित्तविलोकनाय ॥ मातः परं यदपि देवि तथाप्यधन्यस्त्वद्दृष्टिपातरहितोस्म्यहहा हतोऽस्मि ॥ १२ ॥ सत्यं ब्रवीमि शृणु चित्त मदान्ध मूर्ख मा गाः कदापि विषयान्विषमान्विषाक्तान् ॥ ईशीमपारकरुणां भवभीतिभेत्रीमम्बां भजस्व सततं परसौख्यदात्रीम् ॥ १३ ॥ त्वं मे महेशि जननी परमार्तिहर्त्री त्वं मे पिता हिततमस्त्वमहेतुबंधुः ॥ त्वं मे भवाब्धितरणे दृढनौस्त्वमेव दुःखामयाधिहरणे चतुरश्च वैद्यः ॥ १४ ॥ ज्वालां जगज्जननसंहरणस्थितीनां हेतुं गतिं मुषितलज्जितदुःखितानाम् ॥ उन्मोचनां च भवबंधनदुर्गतीनां त्वां नौमि नौमि शरणं शरणागतानाम् ॥ १५ ॥ ज्वालामुखीस्तवमिमं शृणुयात्पठेद्वा यः श्रद्धया परमया बहुभक्तियुक्तः ॥ भूयात्स दग्धबहुजन्मशतार्जिताऽघोऽविघ्नोऽप्यनेकजननाथितराज्यभूमिः ॥ १६ ॥ इति श्रीज्वालामुखीस्तोत्रं समाप्तम् ।

श्रीशारिकास्तोत्रम् ।

ॐ अष्टादशैरसिगदादियुतैर्भुजैर्या त्रातुं समस्तभुवनानि विपद्भयेभ्यः ॥ जागर्त्यशेषजनदुःखहरा परा सा श्रीशारिका दिशतु मङ्गलसन्ततिं नः ॥ १ ॥ उद्यत्सहस्ररविभास्करदीप्तिदीप्तां सिंहासनां शशिकलाभरणां त्रिनेत्राम् ॥ यां चिन्तयन्ति बहुभक्तिरसार्द्रचित्ताः श्रीशारिका० ॥ २ ॥ यत्पादयोः सकृदपीह कृतार्चनो ना भक्त्यान्वितो ह्यनुभवत्यमरप्रभुत्वम् ॥ श्रीराजराजसखिसौख्यनिवासभूमिः श्रीशारिका० ॥ ३ ॥ सौदामनीप्रमदमत्तगजेन्द्रकर्णस्थित्या समापि भजते स्थिरतां विभूतिः ॥ यत्पादपङ्कजयुगाश्रयणात्सदा सा श्रीशारिका०

॥ ४ ॥ यत्कीर्तनश्रवणसंमननोत्थपुण्यं शक्नोति नो गणयितुं बहुधाप्यनन्तः ॥ साऽशेषरोगदलनाय धृतौषधीशा श्रीशारिका० ॥ ५ ॥ श्रीमातृकाभिरुपसेवितपादधूल्या प्रद्युम्नपीठसमवस्थितया ययेश्या ॥ कश्मीरदेशजनता परिपाल्यते सा श्रीशारिका० ॥ ६ ॥ यस्याः प्रदक्षिणपरिक्रमणात्सुभक्त्या पापोऽप्यलंघ्यभवसागरपारमेति ॥ सा शोकमोहपरितापविपत्तिहर्त्री श्रीशारिका० ॥ ७ ॥ मूलालवालमणिपूरकनाभिपद्महृत्कण्ठशिष्टिमतिवाह्य करन्ध्रमेत्य ॥ या मोदते सह शिवेन सहस्रपत्रे श्रीशारिका० ॥ ८ ॥ यस्या अनाहतनिनादसुधारसेन स्नातः परात्परसुखानुभवात्प्रहृष्टः ॥ जीवंश्च मुक्त इव भाति नरोत्तमः सा श्रीशारिका० ॥ ९ ॥ यद्देहसंगतिरसेन सुधापराधिकारकेण विषधारणशक्तियुक्तः ॥ श्रीनीलकण्ठ इति कीर्तिमवाप शंभुः श्रीशारिका दिशतु मंगलसंततिं नः ॥ १० ॥ अमे सुरेशि योगीन्द्रामृतपायनतत्परे ॥ श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ११ ॥ कामे कामितकामानां पूरणे पूर्णताप्रदे ॥ श्रीशारिके० ॥ १२ ॥ चार्वङ्गि कोटिकन्दर्पलावण्ये विश्वमोहिनि ॥ श्रीशारिके० ॥ १३ ॥ टङ्कधारिणि शत्रूणां तिलशो देहखण्डिनि ॥ श्रीशारिके० ॥ १४ ॥ तारे निसर्गगम्भीरभवसागरतारिणि ॥ श्रीशारिके० ॥ १५ ॥ पार्वति त्रिजगन्मातर्हिमवद्वंशपावने ॥ श्रीशारिके० ॥ १६ ॥ यक्षिणीष्टाष्टसिद्धीनां दायिनी देवपूजिते ॥ श्रीशारिके० ॥ १७ ॥ सत्त्वादिशबलेऽनन्तब्रह्माण्डजननीश्वरि ॥ श्रीशारिके० ॥ १८ ॥ कलानिधिकलाकान्तकिरीटकुण्डलोज्ज्वले ॥ श्रीशारिके० ॥

इति श्रीशारिकास्तोत्रं समाप्तम् ।

हमारे क्रयपुस्तक मिलने का पता—

पं० केशवभट्ट ज्योतिषी पाठशाला टीचर, जिला रैणावाड़ी,
महल्ला भाग ज्योगीलङ्गार कश्मीर—श्रीनगर.

क्रयपुस्तकसूची | | मूल्य

(१) नित्यकर्मविधिः (शिक्षा-स्नानविधि-सन्ध्योपासना-नैवेद्यमंत्र-भोजनविधि-पञ्चायतनपूजा-पञ्चगव्यविधि-गुरु-गायत्री-सरस्वती-गौरी-मुकुन्दमालादिस्तोत्रात्मकः) ।)

(२) नित्यकर्मविधिः (स्नान-सन्ध्या-नैवेद्य-भोजन-पञ्च-गव्यादिविध्यात्मकः) ... ... =)

(३) कर्मकाण्डपुस्तकं (सांवत्सरिकपितृकर्मोपयोगि) ...।।।=)

(४) वेदकल्पद्रुमः (हवनक्रियोपयोगी—) ... १।)

(५) मेखलापुस्तकं (ऋचक-विवाह-मेखला-वाग्निकुण्डपूजा-नान्दीश्राद्ध-दर्शकेलि-कन्यासंस्कारात्मकम्) १।।)

(६) शिवपूजा (बहुरूपगर्भ-महिम्नःपार-शिवकवच-निर्वाण-चामर-क्षमापनादिस्तोत्र-दीनाक्रन्द-शिवपूजा-गणेश-स्तवराजात्मिका) .... ≡)

(७) गणेशदुर्गास्तोत्रावली (गणेशस्तोत्रत्रय-गणपतिनित्या-रत्नमाला—शारिका—ब्राह्मीविद्यात्मिका) .... =)

(८) पञ्चस्तवीसमेता सौन्दर्यलहरी .... ।)॥

(९) वटुकपूजा, बहुरूपगर्भस्तोत्र, शिवकवच, महिम-स्तोत्र, दीनाक्रन्द चामरस्तोत्रत्रय, शिवनिर्वाण, शिव-पूजा, षडक्षरस्तोत्रद्वय, क्षमापनस्तोत्र, गणेशस्तवराज गणेशस्तोत्रत्रय, गणपतिविद्या, रत्नमाला, शारिकास्तोत्र, ब्राह्मीविद्या, पञ्चस्तवी, सौन्दर्यलहरी इत्याद्यात्मका (उपयोगिस्तोत्रावलिसमेता कलशपूजा वैश्वदेवा-दिसमेता अतीवोपयोगिनी) ... ... १)

(१०) पार्थिवेश्वरपूजा (कलशपूजादिकोपर्युक्तस्तोत्रादिसं-वलिता योगिस्तोत्रालङ्कृता)... ... ...१)

(११) उपदेशपञ्चकं (रत्नप्रभाटीकयालंकृतम्) .... ≡)

(१२) भक्तविवेकसारः (अज्ञानबोधिनी—योगवासिष्ठसार-आत्मबोध-प्रह्लाद-मुचुकुन्द-रासक्रीडागोपीस्तोत्रयुतः। भिक्षुगीता गणेश, गुरु, गायत्री, मुकुन्दमाला बृह-द्ब्राह्मीविद्या नवग्रहस्तोत्र प्रातःकृत्यादियुतः ....॥≡)

(१३) वटुकपूजा (वैश्वदेवकलशपूजादियुता) स्तोत्रावली विना .... ॥)

पण्डितकेशवभट्टज्योतिर्विदा

संस्कारशोधनाभ्यां सम्पादिता

इयम्

शिवसूर्ययोःसहस्रनामावली ।

मुम्बय्यां

निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा

श्रीसप्तर्षिसंवत्सरे ५०११ विक्रमवत्सरे १९९२

ईस्वी वत्सरे १९३५

परोपकाराय प्राकाश्यं नीता ।

मूल्यं आनकपञ्चकम् ।-)

हमारे क्रेयपुस्तक मिलनेका पताः—

पं० केशवभट्टज्योतिषी पाठशालाटीचर, जिल्ला रैणावारी, महल्ला भागज्योगीलङ्कार, कश्मीर—श्रीनगर.

१ नित्यकर्मविधिः 'नं. १ (स्नानविधि सन्ध्या-नैवेद्यमन्त्र-भोजनविधि-पञ्चगव्यविधि हिन्दी भाषायां इतिकर्तव्यता सहितः ब्राह्मीविद्या च) ... ... =)

२ नित्यकर्मविधिः नं. २ (नं, १ विषय, तथा विष्णुपञ्चायतनपूजा-गणेशकवच-गुरु-गायत्री-गौरीस्तुतिमुकुन्दमालासहितः) ... ... |=)

३ नित्यकर्मविधिः नं. ३ (नं. २ के विषय तथात्रैवर्ण्यवर्णाश्रमाचारशिक्षा-जन्मोत्सवपूज्यपूजा—जन्माष्टमीपूजा जयनारायण-व्याप्तचराचर-अतिभीषण-बहुरूपगर्भोपयोगि स्वच्छन्दध्यानं च) त्रिपञ्चनयनं देवमिति |=)||

४ शिवपूजा (बहुरूपगर्भ-महिम्नःपार-शिवकवच-शिवनिर्वाण-व्याप्तचराचर-अतिभीषण-षडक्षर-पञ्चाक्षर-दीनाक्रन्दनशिवापराधक्षमापन-कैवल्योपनिषत्-शिवपूजागणेशस्तवराजात्मका) ... ... |=)

५ गणेशदुर्गास्तोत्रावली (लाक्षासिन्दूर-अद्रिराजज्येष्ठपुत्र एकदन्तमीशपुत्र इति गणेशस्तोत्रत्रय-गणपतिविद्या-देवीध्यानरत्नमाला-शारिकास्तोत्र-ब्राह्मीविद्यात्मिका) |-)

६ सौन्दर्यलहरी (पञ्चस्तवीसमेता) ... ... |-)

७ देवीपूजा (देवीपूजा-राज्ञीस्तुतिः "याद्वादशर्के"-साहिभरुपभवानीवाक्यमञ्जरी-सरस्वतीस्तुतिश्च) ... |-)

८ चमानुवाक्यम् ... ... =)

९ रुद्रपञ्चकम् (रुद्रमन्त्र-चममन्त्र-सौमारुद्र-दीक्षा-शताध्यायात्मकम्) ... ... |)

सूर्यसहस्रनामावलिः ।

श्रीदेव उवाच । शृणु देवि प्रवक्ष्यामि सूर्यनामसहस्रकम् । यस्य तु पाठमात्रेण सर्वे नश्यन्ति चामयाः ॥ अस्य श्रीसूर्यसहस्र-नाममन्त्रस्य, ब्रह्माऋषिः, गायत्रं छन्दः, सूर्यो देवता, ह्रांबीजं, ह्रीं शक्तिः, सःकीलकं आत्मनोवाङ्मनःकायो० होमे विनियोगः ॥ ह्रांहृदयायनमः ॥ ध्यानं ॥ प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् । सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ भास्कराय विद्महे सहस्ररश्मये धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ ३ ॥ ॐह्रांह्रींसः सूर्यायस्वाहा ॥ ॐभगवते, सर्वलोकेशाय, भूतेशाय भूतभावनाय, भूतात्मने सृष्टिकर्त्रे सृष्टिहर्त्रे जगत्पतये, आदित्याय वरप्रदाय, वीराय वीर-लाय विश्वदीप्ताय विश्वकृते विश्वहृते भक्ताय भोक्त्रे भीमाय, भयापहाय विश्वात्मने पुरुषाय साक्षिणे परंब्रह्मणे परमात्मने प्रतापवते विश्वयोनये विश्वेशाय विश्वतोमुखाय कामिने योगिने महाबुद्धये महसे मनवे अव्ययाय प्रजापतये विश्ववन्द्याय वन्दि-ताय भुवनेश्वराय, भूतभव्यभविष्यात्मने तत्त्वात्मने ज्ञानवते गुणिने सात्त्विकाय राजसाय तामसाय तपस्विने करुणानिधये सहस्रकिरणाय भास्वते भार्गवाय भृगवे ईश्वराय निर्गुणाय निर्दयाय नित्याय नित्यानन्दाय, निराश्रयाय, तपस्विने कालकृते कालाय कामनीयतनवे कृशाय दुर्दर्शाय सुदर्शनाय दाशार्हाय दीनबन्धवे दयाकराय द्विभुजाय अष्टभुजाय धीराय दशबाहवे दशातिगाय दशांशफलदाय, विष्णवे जिगीषवे, जयविजयिने जटिलाय निर्भयाय, भानवे पद्महस्ताय कुशीर-

काय समाहितगतये धात्रे विधात्रे कृतमङ्गलाय मार्तण्डाय लोकभृते त्रात्रे रुद्राय भद्रप्रदायं प्रभवे अरातिशमनाय शान्ताय शङ्कराय कमलासनाय अचिन्त्यवपुषे श्रेष्ठाय महाचीनक्रमेश्वराय महार्तिदमनाय 'तेजोऽसि ।" ॐदान्तायस्वाहां ॥ ध्यानं ॥ ॐमहामोहहराय हरये नियतात्मने कालेशाय दिनेशाय भक्तवत्सलाय कल्याणकारिणे कामदाय कर्कशाय कामवल्लभायं सामगाय पञ्चमाय द्रव्याय ध्रुवाय दीनजनप्रियाय त्रिजटाय रक्तवाससे रक्तवाहनाय रतिप्रियाय कालंयोगिने महानादाय निश्चलाय अदृश्यरूपधृते गम्भीरघोषाय निर्घोषाय घटहस्ताय महामायाय रक्ताम्बरधराय रक्ताय रक्तमाल्यायं अनुलेपनाय सहस्रहस्ताय विजयाय हरिगामिने हरीश्वराय मुण्डाय कुण्डिने भुजङ्गेशाय रथिने सुरथपूजितायं न्यग्रोधवासिने न्यग्रोधाय वृक्षकर्णाय ऊरून्धराय शिखिने दण्डिने जटिने ज्वालिने ज्वालाय तेजोमयायं विभवे हेमाय हेमकराय हारिणे हरिद्रत्नासनस्थिताय हरिदश्वाय जगद्वासिने जगतांपतये इङ्गलाय विरोचनायं विलासिने विरूपाक्षाय विकर्तनाय, विनायकाय विभासाय भासाय भासांपतये पतये मतिमते रतिमंते शोभनाक्षाय विशालाक्षाय विशांपतये बालरूपाय गिरिचराय गीर्पतये गोमतीपतये गङ्गाधराय गणाध्यक्षाय गणसेव्यायं गणेश्वराय गिरीशतनयावासिने सर्ववासिने सतीप्रियाय सत्यात्मकाय सत्यधराय सत्यसन्धाय सहस्रगवे अपारमहिम्ने मुक्तायं मुक्तिदाय मोक्षदायकाय अमूर्तिमते दुर्दराय मूर्ताय तुटिरूपाय लवात्मकाय

प्राणेशाय "तेजोसि" ॐव्यानायँस्वाहा॥ ध्यानं॥ ॐअपानाय स्वाहा, समानाय उदानरूपवते पक्षाय मासाय ऋतवे वर्षाय दिनकालेश्वरेश्वराय अयनाय युगरूपायँ कृतिने त्रेतायुगाय त्रिपादे द्वापराय कलियुगाय कालाय कालात्मने कलिनाशनाय मन्वन्तरात्मकाय देवायँ चक्राय त्रिभुवनेश्वराय वासवाय अग्नये यमाय रक्षसे वरुणाय यादसांपतये वायवे वैश्रवणायँ शैवाय गिरिशाय जलजासनाय अनन्ताय अनन्तमहिम्ने परमेष्ठिने गतज्वराय कल्पान्तकालाग्नये क्रूराय कालायँ दावाग्नये कालसूदनाय महाप्रलयकृतिने कृत्याय कृत्याशिने युगवर्तनाय कालवर्तनाय युगधराय युगादये शर्वरीश्वरायँ आकाशनिधिरूपाय सर्वकालप्रवर्तकाय अचिन्त्याय सुबलाय बालिकावल्लभाय वराय वरदाय वीर्यदाय वाग्मिने वाक्पतये वाग्विलासकाय साङ्ख्येश्वराय वेदरम्याय मन्त्रेशाय तन्त्रनायकाय कुलाचारपराय नुत्याय स्तुतितुष्टाय नतिप्रियाय आलसायँ तुलसीसेव्याय तुष्टाय रोगनिवर्हणाय प्रस्कन्दनाय विभागाय नीरगाय दशदिक्पतये वैराग्याय विमानस्थाय रक्तकुम्भधरायँ आयुधाय महापादाय महाहस्ताय महाकायाय महाशयाय ऋग्यजुषे सामरूपाय त्वष्ट्रे अथर्वधामशाखिलाय सहस्रशाँखिने सदऽसते व्यक्ताय महाकल्पप्रियाय पुंसे कलावृक्षाय मन्दिराय मन्दराचलशोभनाय मेरवे हिमालयाय "तेजोसि" ॐमालिने स्वाहा॥ ध्यानं॥ ॐमलयायस्वाहा मालयद्रुमाय सन्तानाय कुसुमच्छिन्नाय सन्तानफलदाय विराजे क्षीराम्भोधये घृताम्भोधये जलधये क्लेशनाशनायँ रत्नाकराय महामान्याय वेणवे वीणाधराय

वणिजे वसन्ताय सरसामऽन्ताय ग्रीष्माय कल्मषनाशनाय वर्षाकालायैं वर्षपतये शरदम्भोजवल्लभाय हेमन्ताय हेमकेयूराय, शिशिराय शिशुवीर्यदाय सुमतये सुगतये साधवे विष्णवें सस्वराय अम्बिकासुताय सारग्रीवाय महाराजाय सानन्दाय नन्दिसेविताय सुमेरुशिखरवासिने सप्तपातालगोचराय आकाशचारिणे नित्यात्मने विभवे विजयप्रदाय कुलकान्ताय कुलाद्रीशाय विनयाय विजयिने नियताय विश्वम्भराय वियच्चारिणे वियद्रूपायैं वियद्रथाय सुरथाय सुगतये स्तुत्याय वेणुवादनतत्पराय गोपालाय गोपतये गोप्त्रे प्रतिष्ठायै प्रजापतये आवेदनीयाय वेदाक्षाय महादिव्यवपुषे सुराजे निर्जीवाय जीवनाय मन्त्रिणे महार्णवाय निनादभृते वासनायैं आवर्तनाय नित्याय सर्वनाम्ने प्रभवे स्वधिये न्यायनिर्वापणाय शूलिने कपालिने पद्ममध्यगाय त्रिकोणनिलयायैं देवदेवाय बिन्दुमण्डलमध्यगाय बहुमालाय महामालाय दिव्यमालाधराय अजपाय जपाकुसुमसङ्काशाय जपपूजाफलप्रदाय सहस्रमूर्ध्ने देवेन्द्रायैं सहस्रनयनाय रवये सर्वतत्त्वाश्रयाय ब्रध्नाय वीरवन्द्याय विभावसवे विश्वावसवे वसुपतये वसुनाथाय "तेजोसि" ॐविसर्गवतेस्वाहाँ ॥ ध्यानं ॥ ॐआदयेस्वाहा आदित्यलोकेशाय सर्वगामिने कलाश्रयाय भोगीन्द्रशय्याय देवदेवेन्द्राय नरेन्द्राय हव्यवाहनाय विद्याधराय विद्येशायैं यक्षेशाय रक्षणाय गुरवे रक्षायै कुब्जैकवरदाय गन्धर्वकुलपूजिताय अप्सरोवन्दिताय जयाय जेत्रे दैत्यनिबर्हणायैं गुह्यकेशाय पिशाचाय किन्नरपूजिताय कुलजाय सिद्धसेव्याय समाम्नायाय साधुसेव्याय सरित्पतये ललाटाक्षाय

विश्वदेवायँ नियमाय नियमेन्द्रियाय अर्काय अर्ककान्ताय रत्नेशाय अनन्तबाहवे लेपकाय अलिपात्रधराय अङ्गनाय अम्बरेशायँ अम्बरेशयाय अकाराय मातृकानाथाय आदिदेवनाम्ने देवानामादये आकृतिने आरोग्यकारिणे आनन्दविग्रहाय ग्रहाय आलोककृते आदित्याय वीराय अदितिप्राणाधिकाय आकाशरूपाय स्वाकाराय इन्द्रादिस्वरपूजिताय इन्दिरापूजिताय इन्दवे इन्द्राय लोकत्रयाश्रयायँ इनाय ईशानाय चन्द्राय ईशाय ईशानवल्लभाय उन्नतास्याय उन्नतवपुषे उन्नताङ्घ्रिचराय गुरवे उत्पलायँ उच्चलत्केशवते उच्चैर्हयाय गतये सुखिने उकाराय अकारसुखिताय ऊष्माय निधिभूषणाय अनूरुसारथिने उष्णभानवे ऊकारवल्लभाय ऋणहस्ताय ऋलिहस्ताय ऋक्षभूषणाय भूषिताय ऌप्ताङ्गाय ॡआसनस्थाय, ऌॡगण्डयुगोज्ज्वलाय एणाङ्काय अमृतदायँ चीनपट्टभृते बहुशश्वराय एकचक्ररथाय एकाय अनेकचक्षुषे एकदेवाय एकबीजरमणाय एऐओष्टाय अमृताकराय "तेजोसि" ॐवैकर्तनायस्वाहा ॥ ध्यानं॥ ॐकारकारणायस्वाहा, ब्रह्मणे औकारौचित्यमण्डनाय ओऔदन्तालिरञ्जिताय महते महतांपतये अविद्याभूषणाय भूष्याय लक्ष्मीशाय बीजरूपवते अप्स्वरूपाय स्वरमयाय सर्वस्वरपरात्मकाय अंअः-स्वरूपमन्त्राङ्गाय कलिकालनिवर्तकाय कर्मणे एकवरदाय कर्मसाक्षिणे कल्मषनाशनाय कँचध्वंसिने कपिलाय कनकाचलचारकाय कान्ताय कामाय कपये क्रूराय कीर्णाय केशिनिसूदनाय कृष्णाय कँपालिने कपालमोचकाय काशाय कश्मीरघनसारभृते कूजत्किन्नरगीतेष्टाय कुलराजाय कुलन्धराय कुलवासिने कुल-

प्रमोदिने प्रतिपक्षघ्नाय पकाराक्षरमातृकाय फलाय भोगापवर्गसुफलिनीशाय फलात्मकाय फुल्लदम्भोजमध्यस्थाय फुल्लदम्भोजधाराय स्फुटद्युतये स्फुटाकाराय स्फुटिकाचलचारकाय स्फूर्जत्किरणमालिने फकाराक्षरपार्श्वकाय बालाय बालप्रियाय बान्ताय बालध्वान्तहराय बलिने बलादये बर्बरध्वंसिने बर्बरामृतपानकाय बुधाय बृहस्पतये वृक्षाय बृहदश्वाय बृहद्गतये बृहत्पृष्ठाय भीमरूपाय भयापहाय भिदुरप्रियाय भर्गाय भृगवे भृगुस्थायिने भार्गवाय कवये शेखराय भाग्यदाय भानवे दीप्ताङ्गाय "तेजोसि" ॐभनाभयेस्वाहा ॥ ध्यानं ॥ ॐ स्वाहाभमातृकाय महाकालाय महाध्यक्षाय महानादाय महामतये महोज्वलाय मनोहारिणे मनोगामिने मनोभवाय मानदाय मल्लघ्ने मल्लाय मेरुमन्दिरमन्दाराय मन्दारमालाभरणाय माननीयाय मनोमयाय मोदिताय सवित्रे मार्तण्डाय मुण्डमण्डिताय महावराहाय मीनेशाय मेषगाय मिथुनेष्टदाय मदालसाय अमरस्तुत्याय मुरारये वरदाय माधवाय मेदिनीशाय मधुकैटभनाशनाय माल्यवते मेधनाय माराय मेधाविने मुसलायुधाय मुकुन्दाय मुरारिघ्ने सराशिफलदाय मदाय मदनाय मोदकाहाराय मकाराक्षरमातृकाय यज्वने यज्ञेश्वराय यन्ताय योगिनांहृदयस्थिताय यात्रिकाय यज्ञफलदाय यज्ञिने यमलनायकाय योगनिद्राप्रियाय योगकारणाय योगवत्सलाय यष्टिधारिणे यन्त्रेशाय व्योममण्डलमध्यगाय युयुत्सवे जयदाय योगाय योगधर्मानुवर्तकाय योगिनीचक्रमध्यगाय योगीश्वरपूजिताय यान्ताय यक्षैकतिलकाय यक्षराक्षसभूषणाय रामाय रमणशीलाय रत्नभानवे रुरु-

प्रियायै रत्नमौलये रत्नतुङ्गाय रत्नपीठान्तरस्थाय रत्नांशुमाल्याय रत्नाढ्याय रत्नकङ्कणनूपुराढ्याय रत्नाङ्गदलसद्बाहवे रत्नपादुकमण्डिताय रोहिण्याश्रयाय रक्षाकरायै रात्रिज्वरान्तकाय रकाराक्षररूपाय लज्जाबीजाश्रिताय लवाय लक्ष्मीभानवे लतावासिने लसत्कान्तये लोकभृते लोकातङ्कहराय लासावल्लभायै लोमशाय अलिगाय लिङ्गेश्वराय लिङ्गनादाय लीलाकारिणे ललम्बसाय लक्ष्मीवते लोकविध्वंसिने लकाराक्षरभूषणाय "तेजोऽसि" ॐवामनाय स्वाहाँ ॥ ध्यानं ॥ वीरवीरेन्द्राय वाचालाय वाक्पतिप्रियाय वाचामगोचराय वार्ताय वीणायै वेणुधराय वराय वाग्भवाय वालिशध्वंसिने विद्यानकाय कनकाय वकारमातृकामौलये शाम्भवेष्टप्रदाय शुकाय शशिने शोभकराय शान्ताय शान्तिकृते शमनप्रियायै शुभङ्कराय शुक्लवस्त्राय श्रीपतये श्रीयुताय श्रुताय श्रुतगम्याय शरद्बीजमण्डिताय शिष्टसेविताय शिष्टाचाराय शुभाचारायै शेषाय शेवालताडनाय शिपिविष्टाय शिवाय शुक्लाय सेव्याय शाक्षरमातृकाय षडाननाय षट्कारकाय षोडशसुरभूषितायै षट्पदस्वनतोषिणे षडाम्नायप्रवर्तकाय षड्रसास्वादसन्तुष्टाय षकाराक्षरमातृकाय सूर्यबिन्दवे सुखाकराय समस्तसाधकेशाय समस्तकुलशेखराय सुरसूर्याय स्वधासूर्यायै स्वसूर्याय साक्षरेशाय हरित्सूर्याय हरिद्भानवे हव्यैकभुजे हव्यवाहनाय हालासूर्याय सोमसूर्याय हुतसूर्याय हरिसूर्यायै ह्रांसूर्यबीजाय ह्रींसूर्याय हकाराक्षरमातृकाय लंबीजमण्डिताय सूर्याय क्षोणीसूर्याय क्षमापतये क्षुत्सूर्याय क्षान्तसूर्याय लक्ष्यसूर्यायै सदाशिवाय अकार-

सूर्याय क्षःसूर्याय सर्वसूर्याय कृपानिधये भूःसूर्याय भुवःसूर्याय स्वःसूर्याय सूर्यनायकाय ग्रहसूर्याय ऋक्षसूर्याय लग्नसूर्याय महेश्वराय राशिसूर्याय योगसूर्याय मन्त्रसूर्याय अनुत्तमाय तत्वसूर्याय परासूर्याय विष्णुसूर्याय प्रतापवते रुद्रसूर्याय ब्रह्मसूर्याय वीरसूर्याय वरोत्तमाय धर्मसूर्याय कर्मसूर्याय विश्वसूर्याय विनायकाय त्रिलोचनाय "तेजोसि" ॐभुक्तिमुक्तिलक्ष्मीसुखदायस्वाहा १००० इति सूर्यसहस्रनामावली समाप्ता ॥

अथ शिवसहस्रनामावली:।

ॐउपमन्युरुवाच ॥ यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः । सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । यच्छ्रुत्वा मनुजश्रेष्ठः सर्वान्कामानवाप्स्यति ॥ अस्य श्रीशिवसहस्रनामस्तवराजस्य तुण्डिर्ऋषिः, अनुष्टुप्च्छन्दः, श्रीशिवःपरमात्मादेवता आत्मनो० होमे विनियोगः ॥ ॐहृद,-न-शिर,-मः-शिखा,-शि-कव,-वा-नेत्र, य-अस्त्रायफट् । ॐअङ्गुनतर्ज-,मः मध्य, शिअना,-वाकनि,-यकरत ॥ प्राणायामः । ध्यानं, देवं सदा कलशसोमकरं त्रिनेत्रं पद्मासनं च वरदाभयदं सुशुभ्रम् । शङ्खाभयाब्जवरभूषितया च देव्या वामेङ्कितं शमनभङ्गहरं नमामि ॥ तत्पुरुषाय वि ३ ॥ ॐस्थिरायस्वाहा स्थाणवे प्रभवे भानवे प्रभवाय वरदाय वराय सर्वात्मने सर्वविख्याताय सर्वस्मै सर्वाकरोद्भवाय जटिने चर्मिणे शिखण्डिने सर्वाङ्गाय सर्वभावनाय हराय हरिणाक्षाय सर्वभूतहराय विभवे प्रवृत्तये निवृत्तये नियताय शाश्वताय ध्रुवाय श्मशानचारिणे भगवते खचराय गोचरोद्भवाय अभिवाद्याय महाक-

र्मणे तपस्विने भूतभावनाय उन्मत्तवेशप्रच्छन्नाय सर्वलोक-
पितामहाय महारूपाय महाकायाय वृषरूपाय महायशसे महा-
त्मने सर्वभूतात्मने॰ विश्वरूपाय महाहनवे लोकपालाय अन्त-
र्हितात्मने प्रसादाय हयगर्दभये पवित्राय महते नियमाय
नियमाश्रयायँ सर्वकर्मणे स्वयम्भूताय आद्ये आदिकराय
निधये सहस्राक्षाय विशालाक्षाय सोमाय नक्षत्रसाधकाय
चन्द्रायँ सूर्याय शनये केतवे ग्रहाय ग्रहपतये वराय अत्रये
अत्र्यानमस्कर्त्रे मृगबाणार्पणाय अनघायँ महातपसे घोरतपसे
अदीनाय दीनसाधकाय संवत्सरकराय मन्त्रिणे प्रमाणाय पर-
मंतपसे योगिने याज्यायँ महाबीजाय महारेतसे महाबलाय
स्वर्णरेतसे सर्वज्ञाय सुबीजाय बीजवाहनाय दशबाहवे अनि-
मिषाय नीलकण्ठायँ उमापतये विश्वरूपाय स्वयंश्रेष्ठाय बलवी-
राय अबलाय गणाय गणकर्त्रे गणपतये दिग्वाससे "तेजोसि"
ॐकामायस्वाँहाँ ॥ ध्यानं ॥ ॐमन्त्रविदेस्वाहा परमाय मन्त्राय
सर्वभावकराय हराय कमण्डलुधराय धन्विने बाणहस्ताय क-
पालवते अशनिने शतघ्निने॰ खड्गिने पट्टिसिने आयुधिने बृहते
स्रुवहस्ताय स्वरूपाय तेजसे तेजस्कराय निधये उँष्णीषिणे
सुवक्त्राय उदग्राय विनताय दीर्घाय हरिनेत्राय सुतीक्ष्णाय
कृष्णाय सृगालरूपाय सिद्धार्थाय मुण्डायँ सर्वशुभङ्कराय
अजाय बहुरूपाय गन्धधारिणे कपर्दिने ऊर्ध्वरेतसे ऊर्ध्वलि-
ङ्गाय ऊर्ध्वशायिने नभस्तलाय त्रिजटिने चीरवाससे रुद्राय
सेनापतये खगाय अहश्चराय नक्तञ्चराय तिग्ममन्यवे सुवर्चसाय
गजघ्ने दैत्यघ्ने॰ कालाय लोकधात्रे गुणाकराय सिंहशार्दूलरूपाय

आर्द्रचर्माम्बरावृताय कालयोगिने महानादाय सर्वकामाय चतुष्पथाय निशाचराय[६०] प्रेतचारिणे भूतचारिणे महेश्वराय बहुरूपाय बहुधराय स्वर्भानवे अमिताय गतये नृत्यप्रियाय नृत्यतृप्ताय[७०] नर्तकाय सर्वलासकाय घोराय महातपसे पाशाय नित्याय गिरिरुहाय नभसे सहस्रहस्ताय विजयाय[८०] व्यवसायाय अतन्द्रिताय अमर्षणाय धर्षणात्मने यज्ञघ्ने कामनाशकाय दक्ष-यज्ञापहारिणे सुवर्णाय मध्यमाय तेजोपहारिणे[९०] बलिघ्ने मुदि-ताय अर्थाय अजिताय अवराय गम्भीरघोषाय गम्भीराय गम्भी-रबलवाहनाय न्यग्रोधरूपाय "तेजोसि" ॐन्यग्रोधायस्वाहा[१००] ॥ ध्यानं ॥ ॐवृक्षकर्णस्थितयेस्वाहा स्वभुवे सुतीक्ष्णदशनाय महाकायाय महाननाय विष्वक्सेनाय हरये यज्ञाय संयुगापीड-वाहनाय तीक्ष्णतपसे[१०] हर्यश्वाय सहायाय कर्मकालविदे विष्णु-प्रसादिताय यज्वने समुद्राय वडवामुखाय हुताशनसहायाय प्रशान्तात्मने हुताशनाय[१२०] उग्रतेजसे महातेजसे जयाय विजयाय कालविदे ज्योतिषामयनाय सिद्धये सर्वविग्रहाय शिखिने मुण्डिने[१३०] जटिने ज्वालिने मूर्तिजाय दुर्बलाय बलिने वैणविने पणविने तालिने खलिने कालकटंकटाय[१४०] नक्षत्रविग्रहमतये गुणवृद्धिल-याय अगमाय प्रजापतये विश्वबाहवे विभागाय सर्वतोमुखाय विमोचनाय सर्वगणाय हिरण्यकवचोद्भवाय[१५०] मेढ्रजाय बल-चारिणे महीचारिणे स्रुताय सर्वतूर्यनिनादिने सर्वतोद्यपरि-ग्रहाय व्यालरूपाय गुहावासिने हंसमालिने तुरङ्गविदे[१६०] त्रिदशाय त्रिपदीभूमये सर्वबन्धविमोचकाय असुरेन्द्राणांबन्धनाय युधि-शत्रुविनाशनाय सांख्यप्रसादाय दुर्वाससे सर्वसाधुनिषेविताय

प्रस्कन्दनाय विभागज्ञायँ अतुल्याय यज्ञभागविदे सर्वावासाय सर्वचारिणे सुवाससे वासवोपमाय हैमाय हेमकराय अज्ञाय सर्वाधारिणे धरोत्तमाय लोहिताक्षाय महाक्षाय विजयाक्षाय विशारदाय सङ्ग्रहाय निग्रहाय कर्त्रे मृगचर्मनिवासनाय मुख्यायँ मुकुन्ददेहाय काहलये सर्वकामदाय सर्वकामप्रसादाय सुबलाय बलरूपधृषे सर्वकामवराय वरदाय सर्वतोमुखाय "तेजोसि" ॐआकाशनिर्विरूपायस्वाँहाँ ॥ ध्यानं ॥ ॐनिपातिनेस्वाहा अवशाय खमुवे रौद्ररूपाय अंशुभ्यः आदित्याय बहुरश्मये स्ववर्चसिने वसुवेगाय महावेगायँ मनोवेगाय निशाचराय सर्ववासिने श्रियोवासिने उपदेशकराय हरये मुनये आत्मने निरालोकाय सम्भग्नायँ सहस्रदाय पक्षिणे पक्षिरूपाय अतिदीप्ताय विशांपतये उन्मादाय मदनाय कामाय अश्वत्थाय अर्थकरायँ यशसे वामदेवाय वामाय प्राग्दक्षिणाय वामनाय सिद्धयोगिने महर्षये सिद्धार्थाय सिद्धसाधकाय भिक्षवे भिक्षुरूपाय विपणाय मृदवे अक्षयाय महासेनाय विशाखाय षष्टिभागाय गवाम्पतये वज्रहस्ताय प्रतिस्तँम्भिने सैन्यस्तम्भनाय गीतनृत्यकराय तालाय मधवे मधुकलोचनाय वाचस्पत्याय वाजसनाय नित्यमाश्रमपूजिताय ब्रह्मचारिणे लोकचाँरिणे सर्वचारिणे विचारविदे ईशानाय ईश्वराय कालाय निशाचारिणे पिनाकधृषे—निमित्तस्थाय निमित्ताय शम्भँवे नन्दिकराय हरये नन्दीश्वराय नन्दिने नन्दनाय नन्दिवर्धनाय भगहारिणे निहन्त्रे कालाय ब्रह्मविदांवरायँ चतुर्मुखाय महालिङ्गाय चारुलिङ्गाय लिङ्गाध्यक्षाय सुराध्यक्षाय लोकाध्यक्षाय युगावहाय

बीजाध्यक्षाय बीजकर्त्रे अंध्यात्मानुगतये बलाय इतिहासकराय कल्पाय गौतमाय निशाकराय दम्भाय अदम्भाय वैदम्भाय वश्याय "तेजोसि" ॐवश्यकरायस्वाँहाँ ॥ ध्यानं ॥ ॐकलयेस्वाहा लोककर्त्रे पशुपतये महाकर्त्रे अनौषधाय परमाक्षरमूर्तये बलवते शक्राय नीत्यै अंनीत्यै शुद्धात्मने शुद्ध्यमानाय मनोगतये बहुप्रसादाय सुस्वप्नाय धर्षणाय अमित्रजिते वेदकाराय मन्त्र-काराय विंदुषे समरमर्दनाय महामेघनिवासिने महाघोराय वशीकराय अग्निज्वालिने महाज्वालिने हुतिधूम्राय हुताय हविषे वृषणाँय शङ्कराय नित्यंवर्चस्विने धूमकेतनाय नीलाय सर्वाङ्गलुब्धाय शोभनाय निरवग्रहाय स्वस्तिदाय स्वस्तिभोगाय भागिने[४०] भागकराय लघवे उत्सङ्गाय महाङ्गाय महागर्भपरा-यणाय कृष्णवर्णाय सुवर्णाय सर्वदेहिनामिन्द्रियाय महापादाय महाहस्ताँय महाकायाय महायशसे महामूर्ध्ने महामात्राय महा-नेत्राय महालयाय महादन्ताय महाकर्णाय महामेढ्राय महा-हनवे[६०] महासेनाय महाकम्बवे महाग्रीवाय श्मशानधृते महा-वक्षसे महोरस्काय अन्तरात्मने मृगालयाय महाक्रोटये महा-न्तकाय़ँ महौष्ठाय महानासाय लम्बनाय लम्बितौष्ठाय महा-मायाय पयोनिधये महाङ्गाय महादंष्ट्राय महाजिह्वाय महामु-खाँयँ महानखाय महारोम्णे महाकेशाय महाजटाय असपत्नाय प्रसादाय प्रत्ययाय गिरिसादनाय स्नेहनाय अस्नेहनाँयँ अजि-ताय महामुनये वृक्षाकाराय वृक्षहेतवे अनलाय वायुवाहनाय मण्डलिने मेरुधाम्ने वेदवेदाङ्गदर्पघ्ने "तेजोसि" ॐअथर्वशी-र्षोंस्वाँहाँ ॥ ध्यानं ॥ ॐसामास्यायस्वाहा ऋक्सहस्रामितेक्षणाय

यजुःपादभुजाय गुह्याय प्रकाशाय जङ्गमाय अमोघार्थाय अभिगम्याय स्वदर्शनाय उपहारप्रियायँ सर्वकनकाय काञ्चनच्छवये नन्दिने नन्दिकराय भव्याय पुष्करस्थाय वृषस्थिराय द्वापरत्रासनाय आद्याय यज्ञायँ यज्ञसमाहिताय नक्तञ्चराय कालाय मकराय कालपूजिताय सुगणाय गणकार्याय भूतवाहनसारथये भस्मशायिने भस्मगोप्त्रे भस्मरूपाय तरवे गणाय लोकपालाय अलोकाय महात्मने सर्वपूजिताय शुक्लाय त्रिशुक्लाय सम्पन्नायँ शुचये भूतनिषेविताय आश्रमस्थाय कपोतस्थाय विश्वकर्मपतये वराय विशालशाखाय ताम्रौष्ठाय अम्बुजाक्षाय सुनिश्चलायँ कपिलाय कपिलकेशाय आयुषे परात्पराय गन्धर्वाय अदितये ताक्ष्र्याय सुविज्ञेयाय सुशारदाय परश्वधायुधायँ देवाय अर्थकारिणे सुबान्धवाय तुम्बवीणाय महाकोपाय ऊर्ध्वरेतसे जलेशयाय उग्रवंशकराय वंशाय वंशनादायँ अनिन्दिताय सर्वाङ्गरूपिणे मायाविने सुहृदाय अनिलाय अनलाय बन्धनाय बन्धकर्त्रे सुबन्धनविमोचनाय सयज्ञारये सकामारये महादंष्ट्रोद्धृतरिपवे बहुधानिन्दिताय सर्वाय शंकराय शम्बराय अधनाय अमरेशाय महादेवाय विश्वरूपायँ सुरारिघ्ने अहिर्बुध्न्याय अनिलाभाय चिकितानाय हविषे अजैकपादे कापालिने त्रिशंकुवे अजिताय "तेजोसि" ॐशिवायस्वाहा ॥ ध्यानं ॥ ॐधान्वन्तरयेस्वाहा धूमकेतवे स्कन्दाय वैश्रवणोपमाय धात्रे शक्राय विष्णवे मित्राय त्वष्ट्रे ध्रुवायँ वसवे प्रभावाय सर्वगाय वायवे अर्यम्णे सवित्रे रवये उषङ्गाय विधात्रे सन्धात्रे भूतभावनाय अतितीक्ष्णाय हराय वाग्मिने

सर्वकामगुणावहाय पद्मवक्त्राय महावक्त्राय चन्द्रवक्त्राय मनोरमाय बलवते ॐ उपशान्ताय पुराणाय पुण्यचञ्चवे कुरुकर्त्रे कुलावासिने कुरुभूताय गुणौषधाय सर्वाशयाय दर्भशायिने सर्वेषांप्राणिनांपतये देवदेवाय सुखासक्ताय सदसते सर्वरत्नविदे कैलासशिखरावासिने हिमवद्गिरिसंश्रयाय कुलहारिणे कुलकर्त्रे बहुविद्यायैं बहुप्रदाय वाणिज्याय वर्धकिने वृक्षाय बकुलाय चन्दनच्छदाय सारग्रीवाय महाजत्रवे अलोलाय महौषधये सिद्धार्थकारिणे सिद्धार्थाय छन्दोव्याकरणान्तगाय सिंहनादाय सिंहदंष्ट्राय सिंहगाय सिंहवाहनाय प्रभावात्मने जगत्कालाय तालिने लोकहिताय तरवे सारङ्गाय नवचक्राङ्गाय केतुमालिने सुभावनाय भूतालयाय भूतपतये अहोरात्रमनिन्दिताय, सर्वभूतानांवाहित्रे, सर्वभूतानांनिलयाय, करभुवे भवाय अमोघाय संयुताय अश्वाय, भोजनाय, प्राणधारणाय, धृतिमते मतिमंते दक्षाय सत्कृताय युगाधिपाय गोपालाय गोपतये ग्रामाय गोचर्मवसनाय हरये हिरण्यबाहवे "तेजोसि" ॐगुहापालायस्वाहा । ध्यानं ॥ ॐप्रवेशिनांत्रात्रेस्वाहा, प्रकृष्टारये, महाहर्षाय, जितकामाय जितेन्द्रियाय गान्धाराय सुवाससे तपसे कर्मरतये नरायैं महागीताय महानृत्याय अप्सरोगणसेविताय महाकेतवे धनुषे धातवे नैकसानुचराय चलाय आवेदनीयाय आदेशायैं सर्वगन्धसुखावहाय तोरणाय तारणाय वाताय परिधिपतये खेचराय संयोगवर्धनाय वृद्धाय महावृद्धाय गुणाधिपायैं नित्यंधर्मसहायाय देवासुरपतये रतये युक्ताय युक्तबाहवे त्रिदशाय सुपर्वणाय

आषाढाय सुषाढाय ध्रुवायँ हरिणाय हराय वपुषे आवर्तनाय नित्याय वसुश्रेष्ठाय महारथाय शिरोहारिणे विमर्षिणे सर्वलक्षणलक्षितायँ अक्षराय क्षराय योगिने सर्वयोगिने महाबलाय समाम्नायाय असमाम्नायाय तीर्थदेवाय महाद्युतये निर्जीवायँ जीवनाय मन्त्राय अनिन्दिताय बहुकर्कशाय रत्नप्रभूताय रक्ताङ्गाय महार्णवनिनादभृते मूलाय विशालाय अमृतायँ व्यक्ताव्यक्ताय तपोनिधये आरोहणाय अधिरोहाय शीलधारिणे महातपसे सेनाकल्पाय महाकल्पाय योगाय युगकरायँ गतये युगरूपाय महारूपाय पवनाय गहनाय अवधाय न्यायनिर्वापणाय पादाय पण्डिताय अचलोपमायँ बहुमालाय महामालाय सुमालाय बहुलोचनाय विस्ताराय लवणाय कूराय कुसुमाय सुफलोदयाय "तेजोसि" ॐवृषभायस्वाहा ॥ ध्यानं ॥ ॐवृषभाङ्गायस्वाहा, मणिविद्धाय जटाधराय इन्द्राय विसर्गाय सुमुखाय शराय सर्वायुधाय सहसे निवेदनायँ सुधन्वने सुगन्धाढ्याय महाधनुषे गन्धमालिने भाग्यवते सर्वकर्मणामुत्थानाय मन्थानाय बहुलाय बाहवे सकलायँ सर्वलोचनाय नराय तालाय करस्थालिने ऊर्ध्वसंहननाय वहाय वृत्रपतये सुविख्याताय लोकाय सर्वाश्रयाय[३०] क्रमाय मुण्डाय विरूपाय विकृताय दण्डिने कुण्डिने विकुर्वाणाय हर्यक्षाय ककुभाय वज्रिणे[४०] शतजिह्वाय सहस्रपादे, सहस्रमूर्ध्ने देवेन्द्राय सर्वभूतमयाय गुरवे सहस्रबाहवे सर्वाङ्गाय शरण्याय सर्वलोककृते[५०] विपन्नाशाय मधवे मन्त्राय कनिष्ठाय कृष्णपिङ्गलाय ब्रह्मदण्डविनिर्मात्रे शतघ्नीशतपाशभृते पद्मगर्भाय महागर्भाय ब्रह्मगर्भाय[६०] जलोद्भवाय गभस्तिने ब्रह्मकृते ब्रह्मणे ब्रह्मविदे ब्राह्मणाय गतये अनन्तरूपाय अनेका-

त्मने तिग्मांशवे[७०] आत्मसम्भवाय ऊर्ध्वगात्मने पशुपतये वात-
रंहसे मनोजवाय चन्दनाय पद्ममालाग्र्याय अगण्याय अन्तरं-
गाय अन्तर्याय[८०] कर्णिकारमहास्रग्विणे नीलमौलये पिनाकधृगे
उमापतये उमाकान्ताय जाह्नवीभृते अनम्बराय वराय वराहाय
वरदाय[९०] वरेशाय सुमहास्तनाय महाप्रसादाय दमनाय शत्रुघ्ने
श्वेतपिङ्गलाय प्रीतात्मने परमात्मने प्रयतात्मने "तेजोसि" ॐप्र-
धानभृतेस्वाहा[१००] ॥ ध्यानं ॥ ॐसर्वपार्श्वसुतायस्वाहा, ताक्षार्य धर्म-
साधारणाय अचलाय चराचरात्मने सूक्ष्माय अमृताय गोवृषे-
श्वराय साध्यर्षये कृपये[१०] आदित्याय विवस्वते सवित्रे अमृताय
व्यासाय सर्वस्यसंक्षेपाय सर्वस्यविस्ताराय पर्ययाय अनराय
ऋतुभ्यः[२०] संवत्सराय मासेभ्यः पक्षाभ्यां सांख्यसमापनाय
कलाभ्यः काष्ठाभ्यः लवेभ्यः मात्राभ्यः मुहूर्ताय अह्ने[३०] क्षणदायै
क्षणेभ्यः विश्वक्षेत्राय प्रजाबीजाय लिङ्गाय आद्याय निर्गमाय
सते असते व्यक्ताय[४०] अव्यक्ताय पित्रे मात्रे पितामहाय स्वर्ग-
द्वाराय प्रजाद्वाराय मोक्षद्वाराय त्रिविष्टपाय निर्वाणाय ह्लाद-
नाय[५०] ब्रह्मलोकाय परागतये देवासुरविनिर्मात्रे देवासुरपराय-
णाय देवासुरगुरवे देवाय देवासुरनमस्कृताय देवासुरमहामा-
त्राय देवासुरमहाश्रयाय देवासुरमहाध्यक्षाय[६०] देवासुरगणा-
ग्रण्ये देवातिदेवाय देवर्षये देवासुरसुपूजिताय देवासुरेश्वराय
विश्वस्मै देवासुरमहेश्वराय सर्वदेवमयाय अचिन्त्याय देवा-
त्मने[७०] अर्थसाधकाय उद्भिदे त्रिविक्रमाय वैद्याय विरजसे
विरजोम्बराय ईड्याय हस्तीश्वराय व्याघ्राय देवसिंहाय[८०] नरर्ष-
भाय विबुधाग्रचरश्रेष्ठाय सर्वदेवोत्तमोत्तमाय गुहाकान्ताय
अतिनिसर्गाय स्वनाम्नासर्वपावनाय भृङ्गिणे भृङ्गिप्रियाय बभ्रवे

राजराजातिपूजितार्थं अभिरामाय सुरगणातिरामाय सर्वसाधनाय ललाटाक्षाय विश्वदेवाय सर्वाधिब्रह्मवर्चस्विने स्थावराणांपतये नियतेन्द्रियवर्धनाय सिद्धार्थाय सर्वभूतार्थाय नियतव्रतसंस्थिताय व्रतादये परंब्रह्मणे भक्तानांपरमागतये सुशान्तदीप्ततेजस्विने श्रीमते श्रीवर्धनाय ॥"तेजोसि"। ॐजगतेस्वाहा ॥ उपमन्युरुवाच। अष्टोत्तर-सहस्रेण जप्यमानस्य शङ्करः। यथाभीष्टं ददात्याशु प्रयतस्य न संशयः ॥ इति महाभारते शान्तिपर्वणि शिवसहस्रनामस्तुतिः ॥

अथ नरकोत्तारणस्तोत्रम् ॥

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ नारायणं जगद्बीजं पुराणं पुरुषोत्तमम्। परिपृच्छति धर्मात्मा पाण्डुपुत्रो युधिष्ठिरः ॥ श्रीयुधिष्ठिर उवाच ॥ किं जपन्पुरुषो मुच्येद्यमलोकैकशासनात्। तन्मे कथय तत्त्वेन भक्तस्य तव केशव ॥ श्रीभगवानुवाच ॥ शृणु राजन्महाबाहो धर्मात्मन्पाण्डुनन्दन। अहं ते कथयिष्यामि नरकोत्तारणं महत् ॥ ॐकारात्मन्नमस्तेऽस्तु ऋग्यजुःसामरूपिणे। यज्ञात्मने नमस्तेस्तु सर्वशास्त्रात्मने नमः ॥ भूतभव्यजगन्नाथ सर्वभूत जगत्पते। नमस्ते सर्वलोकेश महापुरुष पूर्वज। नमोमत्स्याय कूर्माय मूलप्रकृतये नमः। नमो यज्ञवराहाय नरसिंहाय वै नमः। त्रिविक्रमाय रामाय वैकुण्ठाय नराय च। नमस्तेऽश्वमुखायापि कूटस्थायाक्षराय च। अनन्तायाच्युतायापि जामदग्न्याय वै नमः। मधुकैटभनाशाय शङ्कराय नमोनमः। रामाय विश्वरूपाय वासुदेवाय वै नमः। पीताम्बराय देवाय युगवर्णाय वै नमः ॥ स्थित्युत्पत्तिविनाशानां हेतुरूपाय वै

नमः । ब्रह्मणे वायुरूपाय रुद्ररूपाय वै नमः । धनदेशस्वरूपाय मोक्षरूपाय वै नमः । सोमाय सूर्यरूपाय हविर्गन्धाय वै नमः । परमेश्वररूपाय नमः श्रीवत्सधारिणे । बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोसि नमोस्तु ते । लक्ष्मीप्रियाय देवाय ह्यतसीश्यामरूपिणे । प्रसीद मम दीनस्य भक्तियुक्तस्य माधव ॥ रौरवान्नरकाद्घोरात्पाहि मां गरुडध्वज । असिपत्रवनात्पाहि शङ्खचक्रगदाधर । कुम्भीपाकान्महादेव पाहि मां शरणागतम् । अवीचेः कालसूत्राच्च पाहि मां दुःखनाशन । सूच्यागारादम्बरीषात्पाहि मां मधुसूदन । असृक्केशास्थिवाहिन्या वैतरण्याश्चतुर्भुज । पाहि मां कर्मसाक्षी त्वं शरणागतवत्सल । इक्षुपीडनकैर्यन्त्रैः पीड्यन्ते यत्र मानवाः । देशात्तस्माज्जगन्नाथ पाहि मां भक्तवत्सल । तप्तवालुकदेशश्च शल्मल्यायामवह्लितः । तद्देशात्पुण्डरीकाक्ष पाहि मां करुणानिधे । क्रकचैर्यत्र पाट्यन्ते मानुषा देवदारुवत् । तेभ्योपि रक्ष मां हंस शरणागतवत्सल । सारमेयैश्च खाद्यन्ते यामे वर्त्मनि मानवाः । महाभयात्प्रभो तस्मात्केशव क्लेशनाशन । अन्ये च नरका घोरा यमलोके प्रतिष्ठिताः । तेभ्योपि रक्ष मां हंस नमस्तेऽस्तु सहस्रशः । तिर्यग्योनिगतस्यापि भक्तिर्मे तव केशव । अचला स्याद्यथा कृष्ण तथा कुरु वरप्रद । बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षवान् । सर्वतो रक्ष मां हंस सर्वात्मन् सर्वतोमुख । नमस्ते देवदेवेश यथा पास्यऽखिलं जगत् । स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर । कृष्णाच्युत हृषीकेश सर्वभूतेश केशव । महात्मन् पाहि मां भक्तं वासुदेव नमोस्तुते । इति स्तवन्नरो राजन्सदा नारायणं प्रभुम् । यमलोकं न पश्येच्च नरकं च कुतः पुनः । स्मरन्नपि सदा मर्त्यः शृण्वन्नपि

युधिष्ठिर । महापातकजैर्वीरैर्मुच्यते सर्वकिल्बिषैः । आयुरारोग्यमैश्वर्यं श्रियं मेधां तथा बलम् । प्राप्नोति च पठन्नित्यं तद्विष्णोः परमं पदम् । भयकान्तारदुर्गेषु तथा संसारसागरात् । सत्यं संतरते मर्त्यः स्तवस्याप्यनुकीर्तनात् । अन्ते सायुज्यमाप्नोति तद्विष्णोः परमं पदम् ॥ इति श्रीनरकोत्तारणस्तोत्रं सम्पूर्णम् ॥

अथ नारायणकवचम् ॥

श्रीराजोवाच ॥ यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रैलोक्या बुभुजे श्रियम् ॥ १ ॥ भगवंस्तत्समाख्याहि वर्म नारायणात्मकम् । यथाऽततायिनः शत्रून्येन गुप्तोऽजयन्मृधे ॥ २ ॥ श्रीशुकउवाच ॥ वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायाऽनुपृच्छते । नारायणाख्यं वर्माऽह तदिहैकमनाः शृणु ॥ ३ ॥ विश्वरूप उवाच ॥ धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४ ॥ नारायणमयं वर्म संनह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥ मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ॐनमोनारायणायेति विपर्ययमथापिवा ॥ ६ ॥ करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥ न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखयाऽदिशेत् ॥ ८ ॥ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेन्नरः ॥ ९ ॥ सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् । "ॐविष्णवेनमः" इति ॥ १० ॥ आत्मानं

परमं ध्यायेद्ध्येयं षड्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥ ॐअस्यश्रीनारायणकवचमन्त्रस्य, श्रीविश्वरूपऋषिः, गायत्रं छन्दः, श्रीपरमात्मानारायणो देवता, ॐनमोनारायणायेति बीजं, ॐनमो भगवते वासुदेवायेति शक्तिः, ॐविष्णवेनमः इतिकीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीविष्णुप्रीत्यर्थे पाठे विनियोगः ॥ ॥ विश्वरूपऋषयेनमः शिरसि, गायत्रंच्छन्दसेनमः मुखे, श्रीपरमात्मा नारायणोदेवतायैनमः हृदि, ॐनमोनारायणायेतिवीजायनमः गुह्ये, ॐनमोभगवतेवासुदेवायेतिशक्तये नमः नाभौ, ॐविष्णवेनमइतिकीलकायनमः पादयोः, पाठेविनियोगायनमः सर्वाङ्गेषु ॥ ॐॐनमः पादयोः, ॐननमः जानुनोः, ॐमोनमः ऊर्वोः, ॐनानमः उदरे, ॐरानमः हृदि, ॐयनमः उरसि, ॐणानमः मुखे, ॐयनमः शिरसि ॥ ॐॐनमः दक्षिणहस्ततर्जन्यैनमः, ॐननमः दक्षिणमध्यमायैनमः, ॐमोनमः दक्षिणानामिकायैनमः, ॐभनमः दक्षिणकनिष्ठिकायैनमः, ॐगनमः वामकनिष्ठिकायैनमः, ॐवनमः वामानामिकायैनमः, ॐतेनमः वाममध्यमायैनमः, ॐवानमः वामतर्जन्यैनमः, ॐसुनमः वामाङ्गुष्ठाद्यपर्वणेनमः, ॐदेनमः वामाङ्गुष्ठान्त्यपर्वणेनमः, ॐवानमः दक्षिणाङ्गुष्ठाद्यपर्वणेनमः, ॐयनमः दक्षिणाङ्गुष्ठान्त्यपर्वणेनमः ॥ ॥ ॐॐनमः हृदयायनमः, ॐविनमः शिरसेस्वाहा, ॐष्नमः भ्रुवोर्मध्ये, ॐणनमः शिखायैवषट्, ॐवेनमः नेत्राभ्यांवौषट्, ॐननमः सर्वसन्धिषु, ॐमःनमः अस्त्रायफट् दिग्बन्धेविनिर्दिशेत् ॥ ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान्कनककुण्डलवा-

१ ईश्वररूपं २ ऐश्वर्यादिभिर्भगशब्दवाचिभिः ।

न्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ ॐनमो नारायणाय
पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ ३ ॥
ॐहरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दराऽरिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १ ॥
जलेषु मा रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः ॥२॥
दुर्गेष्वऽटव्याजिमुखादिषु[3] प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ ३ ॥
रक्षत्वऽसौ माऽध्वनि यज्ञकल्पः[4] स्वदंष्ट्रयोन्नीतधरो[5]वराहः । रामो[6]-
ऽद्रिकूटेष्व[7]ऽथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥४॥
मामुग्रधर्माद[8]ऽखिलात्प्रमादान्नारायणः पातु नरश्च हासात्[9] । दत्त[10]-
स्त्वऽयोगा[11]दथ योगनाथः पायाद्गुणेशः कपिलः कर्मब-
न्धात् ॥ ५ ॥ सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि[12]
देवहेलनात् । देवर्षिवर्य[13]ः पुरुषार्चनान्तरात्[14] कूर्मो हरिर्मां
निरयादशेषात् ॥ ६ ॥ धान्वन्तरिर्भगवान्पात्वऽपथ्याद्द्वन्द्वाद्भ
यादृषभो निर्जितात्मा । यज्ञश्च लोकादऽवताज्जनान्ताद्[15] बलो[16]
गणात्[17]क्रोधवशादहीन्द्रः ॥ ७ ॥ द्वैपायनो भगवानऽप्रबोधाद्बु-

---

३ संग्रामोपक्रमादिषु। ४ यज्ञैरवयवरूपैः कल्प्यन्ते निरूप्यन्ते। ५ उद्धृतभूः।
६ जामदग्न्यः। ७ गिरिशिखरेषु। ८ अभिचारादिलक्षणात्। ९ गर्वात्।
१० दत्तात्रेयः। ११ योगभ्रंशात्। १२ पथि यद्देवानां हेलनं नमस्कारादिमकृत्वा
गमनं तस्मात्। १३ नारदः। १४ भेदबुद्ध्याऽन्यदेवपूजनात् ॥ पुरुषार्चनान्त-
रादिति पाठे तु पुरुषार्चनस्यान्तरात् देवपूजाच्छिद्राद्द्वात्रिंशदऽपराधरूपात्।
१५ जनापवादात्। १६ जननिमित्तो योऽन्त उपघातस्तस्मात्। बलभद्रः
कृतान्तादिति पाठे तु कालात्। १७ क्रोधवशात्सर्पाणां गणात्। शेषनागः।

धस्तु पाषाण्डगणात्प्रमादात् । कल्किः कलेः कालमलात्[18]प्रपातु
[19]धर्मावनायोरुकृतावतारः ॥ ८ ॥ मां केशवो गदया प्रातरव्या-
द्गोविन्द आसङ्गव[20]मात्तवेणुः । नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ ९ ॥ देवोऽपराह्णे मधुहोग्र-
धन्वा सायं त्रिधामा[21]ऽवतु माधवो माम् । दोषे[22] हृषीकेश
उतार्धरात्रे[23] निशान्त एकोऽवतु पद्मनाभः ॥ १० ॥ श्रीवत्स-
धामाऽपररात्र ईशः प्रत्यूषकालेऽसिधरो जनार्दनः । दामोदरो-
ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥११॥
चक्रं युगान्तानलतिग्मनेमि[24] भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्य[25]रिसैन्यमाशु कक्षं यथा वातसखो हुताशः
॥ १२ ॥ गदेऽशनि[26]स्पर्शनविस्फुलिङ्गे ! निष्पिण्ढि निष्पिण्ढ्य-
ऽजितप्रियाऽसि । कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्ण-
याऽरीन् ॥ १३ ॥ त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रह[27]घो-
रदृष्टीन् । दरेन्द्र[28] विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि
कम्पय ॥ १४ ॥ त्वं तिग्मधारा[29]ऽसिवराऽरिसैन्यमीशप्रयुक्तो

---

१८ कालमलभूतात् । १९ धर्मरक्षणाय महान्कृतोऽवतारो येन । २० अहोरात्र-क्षणानभिव्याप्य । २१ ब्रह्मादित्रिमूर्तिः । २२ प्रदोषे । २३ अर्धरात्रपर्यन्ते निशान्ते चैक एव पद्मनाभः । २४ युगान्तानलवत्तिग्मा तीक्ष्णा नेमिर्यस्य तच्चक्रं भगवता प्रयुक्तं सदरिसैन्यं । २५ अतिशयेन दहति । तस्यायं स्वभाव एव, नतु प्रार्थनीयमित्यर्थः । २६ अशनिवत्स्पर्शो येषां ते विस्फुलिङ्गा यस्यास्तस्याः सम्बोधनं । हे गदे! त्वमजितस्य प्रियाऽसि अहमच्युतस्य दासः, अतः कूष्माण्डादीन्निष्पिण्ढि २ संचूर्णय २ । सर्वत्र वीप्साऽतिशीघ्रत्वाय । २७ विप्रग्रहा ब्रह्मराक्षसा चान्ये घोरदृष्टयस्तान् । २८ हे पाञ्चजन्य । २९ तिग्मा धारा यस्य । हे तिग्मधार! खड्गश्रेष्ठ ।

मम छिन्द्धिछिन्धि । चक्षूंषि चर्मन्! शतचन्द्र[३०] छादय द्विषा-मघोनां[३१] हर पापचक्षुषाम्[३२] ॥ १५ ॥ यन्नो[३३] भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एवच । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य[३४] एव वा ॥ १६ ॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः[३५] ॥ १७ ॥ गरुडो भगवान् स्तोत्रस्तोभ[३६]श्छन्दोमयः[३७] प्रभुः । रक्षत्वऽशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥१८॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः[३८] । बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः[३९] ॥ १९ ॥ यथाहि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ २० ॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ २१ ॥ तेनैव सत्यमानेन[४०] सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ २२ ॥ विदिक्षु दिक्षूर्ध्वमधः समन्तादऽन्तर्बहिर्भगवान्नारसिंहः । प्रहापयंल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः[४१] ॥ २३ ॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यऽञ्जसा येन दंशितोऽसुरयूथपान् ॥ १ ॥ एतद्धारयमाणस्तु यंयं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ २ ॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राज-

---

३० शतचन्द्राकाराणि मण्डलानि यस्मिन् हे शतचन्द्रचर्मन् । ३१ अघवतां द्विषां । ३२ उग्रदृष्टीनां चक्षूंषि हर । ३३ येभ्यो भयं । ३४ पापेभ्यः । ३५ इष्टविघातकाः । ३६ स्तोत्राणि बृहद्रथन्तरादि सामानि तैः स्तोभ्यते संस्तूयते इतिस्तोत्रस्तोभः ॥ ३७ वेदमूर्तिः । ३८ यथार्थं चेत् । ३९ पार्षदान्भूषयतीति । ४० सत्यभूतेन प्रमाणेन । ४१ ग्रस्तानि समस्तानि दिग्गजविषशस्त्रजलवाय्वऽग्न्यादीनां तेजांसि प्रभावा येन सः ।

दस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३ ॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ४ ॥ तस्योपरि विमानेन गन्धर्वपति- रेकधा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ५ ॥ गगनान्न्यपतत्सद्यः सविमानो ह्यऽवाक्शिराः । स वालखि- ल्यवचनादऽस्थीन्याधाय विस्मितः ॥ ६ ॥ प्रास्य प्राचीसर- स्वत्यां स्नात्वा धाम स्वमऽन्वगात् ॥ श्रीशुकः ॥ य इदं शृणु यात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतोभयात् ॥ ७ ॥ एतां विद्यामधिगतो विश्वरूपाच्छत- क्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ८ ॥ इतिश्रीभागवते षष्ठस्कन्धे नारायणवर्मनामाऽष्टमोऽध्यायः ॥ ॥

अथ पञ्चमुखहनुमत्कवचम्

अथ श्रीपञ्चवदनायाञ्जनेयायनमः । ॐअस्य श्रीपञ्चमुखहनुम- त्कवचमन्त्रस्य, ब्रह्माऋषिः, गायत्रं च्छन्दः, पञ्चमुखविराट्हनुमान् देवता, ह्रींवीजं, श्रींशक्तिः क्रौंकीलकं क्रूंकवचं, क्रैं अस्त्रायफट् पाठे विनियोगः ॥ इति दिग्बन्धः ॥ श्रीगरुड उवाच ॥ अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् । २ । पूर्वं तु वारुणं वक्त्रं कोटिसूर्यसम- प्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् । ३ । अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयना- शनम् । ४ । पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् । सर्व- नागप्रशमनं विषभूतादिकृन्तनम् । ५ । उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्त-

नम् । ६ । ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् । ७ । जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् । ८ । खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् । ९ । भिन्दिपालं ज्ञानमुद्रां दशभिर्हरिपुङ्गवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् । १० । प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । ११ । सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् । पञ्चास्यमच्युतमनेकविचित्रवर्णं वक्त्रे शशाङ्कशिखरं कपिराजवर्यम् ॥ पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि । १२ । मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर । १३ । ॐहरिमर्कट मर्कट मंत्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता । १४ । ॐहरिमर्कटाय स्वाहा । ॐनमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहरणाय स्वाहा । ॐनमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । ॐनमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । ॐनमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा । ॐनमो भगवते पंचवदनायोर्ध्वमुखाय हयग्रीवाय सकलजीववशंकराय स्वाहा ॥ ॐअस्यश्रीपञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः, अनुष्टुपछन्दः पञ्चमुख वीरहनुमान् देवता, हनुमानितिबीजं, वायुपुत्र इति शक्तिः, अञ्जनीसुत इति

कीलकं, श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ "इति ऋष्यादिकं विन्यस्य" । ॐअञ्जनीसुताय अङ्गुष्ठाभ्यांनमः । ॐरुद्रमूर्तये तर्जनीभ्यांनमः । ॐवायुपुत्राय मध्यमाभ्यांनमः । ॐअग्निगर्भाय अनामिकाभ्यांनमः । ॐरामदूताय कनिष्ठिकाभ्यांनमः । ॐपञ्चमुखहनुमते करतलकरपृष्ठाभ्यांनमः । (इतिकरन्यासः) । ॐअञ्जनीसुताय हृदयायनमः । ॐरुद्रमूर्तये शिरसेस्वाहा । ॐवायुपुत्राय शिखायै वषट् । ॐअग्निगर्भाय कवचाय हुं । ॐरामदूताय नेत्रत्रयायवौषट् । ॐपञ्चमुखहनुमते अस्त्रायफट् ॥ "पञ्चमुखहनुमते स्वाहा" इतिदिग्बन्धः ॥ अथ ध्यानं ॥ वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं दैदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् । १ ॥ अथ मन्त्रः ॥ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय सञ्जीवनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट् प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ॥ ॐहरिमर्कटमर्कटाय बंबंबंबंबं वौषट्स्वाहा । ॐहरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । ॐहरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणायस्वाहा । ॐहरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा । ॐहरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनायस्वाहा । ॐहरिमर्कट-

मर्कटाय ॐटंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनायस्वाहा। ॐकंखंगंघंङंचंछंजंझंञंटंठंडंढंणंतंथंदंधंनंपंफंबंभंमंयंरंलंवंशंषंसंहंळंक्षंस्वाहा। इति दिग्बन्धः॥ ॐपूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणायस्वाहा। ॐदक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐह्रांह्रींह्रूंह्रैंह्रौंह्रः सकलभूतप्रेतदमनायस्वाहा। ॐपश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहरायस्वाहा। ॐउत्तरमुखायादिवराहायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमतेस्वाहा। ॐऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकायस्वाहा। ॐअञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमतेस्वाहा। भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रहपरयंत्रपरतन्त्रोच्चाटनायस्वाहा। सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजंस्वाहा॥ इदं कवचं पठित्वातु महाकवचं पठेन्नरः। एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम्। १५। द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्। त्रिवारं तु पठेन्नित्यं सर्वसम्पत्करं शुभम्। १६। चतुर्वारं पठेन्नित्यं सर्वलोकवशंकरम्। षड्वारं पठेन्नित्यं सर्वदेववशङ्करम्।१७। सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्। १८। अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम्। च नववारं पठेन्नित्यं राजभोगमवाप्नुयात्। १९। दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्। रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम्॥ २०॥ कवचस्मरणेनैव महाबलमवाप्नुयात्। २१। इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं॥

अथ वज्रपञ्जराख्यसूर्यकवचम् ॥

भैरवः ॥ यो देवदेवो भगवान्भास्करो महसां निधिः । गायत्रीनायको भास्वान् सवितेति प्रगीयते ॥ तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ सर्वपापहरं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् । सर्वशत्रुसमूहघ्नं सङ्ग्रामे विजयप्रदम् । सर्वतेजोमयं दिव्यं देवदानवपूजितम् ॥ रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवाननिर्गतम् ॥ ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् । धारणादऽस्य देवेशि ब्रह्मा लोकपितामहः ॥ विष्णुर्नारायणो देवि रणे दैत्याञ्जयत्यपि । शङ्करः सर्वलोकेशो वासवोपि दिवस्पतिः । ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः । मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ यो धारयेद्भुजे मूर्ध्नि रविवारे महेश्वरि । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ बहुनोक्तेन किं देवि कवचस्याऽस्य धारणात् । इह लक्ष्मीधनारोग्यवृद्धिर्भवति नान्यथा ॥ परत्र परमा मुक्तिर्देवानामपि दुर्लभा । कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्री छन्द इत्युक्तं देवता सविता स्मृता ॥ मायावीजं शरच्छक्तिर्नमः कीलकमीश्वरि । सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ अस्य श्रीवज्रपञ्जराख्यसूर्यकवचस्य, ब्रह्माऋषिः, गायत्रं छन्दः, सविता देवता, ह्रीं वीजं, सः शक्तिः, नमः कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं, असुककामनासिद्ध्यर्थे पाठे विनियोगः ॥ ध्यानं ॥ प्रत्यक्षदेवं० ॥ अंआंइंईं शिरः पातु ओंसूर्यो मन्त्रविग्रहः । उंऊंऋंॠं ललाटं मे ह्रांरविः पातु चिन्मयः ॥ ऌंॡंएंऐं पातु नेत्रे ह्रींम-

भाऽरुणसारथिः । ओंऔंअंअः श्रुती पातु सः सर्वजगदीश्वरः ॥ कंखंगंघं पातु गण्डौ मे सूरः सुरपूजितः । चंछंजंझं च मे नासां पातु मामर्यमा प्रभुः ॥ टंठंडंढं मुखं पायाद्यं योगीश्वरपूजितः । तंथंदंधं गलं पातु नंनारायणवल्लभः ॥ पंफंबंभं ममस्कन्धौ पातु मां महसां निधिः ॥ यंरंलंवं भुजं पातु मूलं सकलनायकः । शंषंसंहं पातु वक्षो मूलमन्त्रमयो ध्रुवः ॥ लंक्षः कुक्षिं सदापातु ग्रहनाथो दिनेश्वरः ॥ ङंञंणंनंमं मे पातु पृष्ठं दिवसनायकः ॥ अंआंइंईं उंऊंऋंॠं नाभिं पातु तमोपहः । लृंॡंएंऐंओंऔंअंअः लिङ्गं मेऽव्याद्ग्रहेश्वरः ॥ कंखंगंघंचंछंजंझं कटिं भानुर्ममाऽवतु । टंठंडंढंतंथंदंधं जानू भास्वान्ममावतु ॥ पंफंबंभंयंरंलंवं जङ्घे मेऽव्याद्दिवाकरः । शंषंसंहंलंक्षं पातु मूलं पादौस्त्रयीतनुः ॥ ङंञंणंनंमं मे पातु सविता सकलं वपुः । सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदाऽवतु ॥ बुधो मां दक्षिणे पातु नैर्ऋत्यां गुरुरेव माम् । पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ॥ उत्तरे मां तमः पायादैशान्यां मां शिखी तथा । ऊर्ध्वं मां पातु मिहिरो मामधस्ताज्जगत्पतिः । प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः । सायं वेदप्रियः पातु निशीथे निष्कलापतिः ॥ सर्वत्र सर्वदा पातु सूर्यो मां चक्रनायकः । रणे राजकुले द्यूते विवादे शत्रुसङ्कटे ॥ सङ्ग्रामे च ज्वरे घोरे पातु मां सविता प्रभुः ॥ ॐॐॐउउऊंउऊंहसमयः सूर्योऽवतान्मां भयाद्ध्रांह्रीं-ह्रींहहहाहसौंहसहसौ हंसोऽवतात्सर्वतः । सःसःसःससस: नृपा-द्वनचराच्चौराद्रणात्सङ्कटात्पायान्मां कुलनायकोऽपि सविता ॐह्रींहसौ सर्वदा ॥ द्रांद्रींद्रूं दधतं तथा च तरणिभां भैर्भया-द्भास्करो रांरींरूंरुरुरूंर विज्वरभयात्कुष्ठाच्च शूलामयात् ।

अंअंआंविविवीं महामहमयं मां पातु मार्तण्डको मूर्ध्न्यास्त-
तनुः सदाऽवतु परंहंसः सहस्रांशुमान्[१६] ॥ इति श्रीकवचं दिव्यं
वज्रपञ्जरकाभिधम् । सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम्[१] ॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं
सर्वश्रेयस्करं शिवे[२] ॥ लिखित्वा रविवारे तु तिष्ये वा जन्मभे
प्रिये । अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति[३] ॥ अर्कक्षीरेण
पुण्येन भूर्जपत्रे महेश्वरि । कनके काष्ठलेखन्या कवचं भास्क-
रोदये[४] ॥ श्वेतपत्रेण रक्तेन श्यामेन वीष्टयेत्कुटिम् । सौवर्णेनाथ
संवीष्ट्य धारयेन्मूर्ध्नि वा भुजे[५] ॥ रणे रिपूञ्जयेद्देवि वादीन्सदसि
जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत्[६] ॥ कण्ठस्था
गुटिका देवि कुक्षिस्था रोगनाशिनी । शिरःस्था गुटिका देवि
राजलोकवशङ्करी[७] ॥ भुजस्था धनदा देवि तेजोबुद्धिविवर्धिनी ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना[८] ॥ कण्ठे सा
धारयेन्नित्यं बहुपुत्रान्प्रजायते । यस्य देहे भवेन्नित्यं गुटिकैषा
महेश्वरि[९] ॥ महास्त्राणीन्द्रमुख्यानि ब्रह्मास्त्रादीनि पार्वति । तद्देहं
प्राप्य व्यर्थानि भविष्यन्ति न संशयः[१०] ॥ त्रिकालं यः पठेन्नित्यं
कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि सविता वरदो भवेत्[११] ॥
अज्ञानात्कवचो देवि पूजयेद्यस्त्रयीतनुम् । तस्य पूजान्वितं पुण्यं
जन्मकोटिषु निष्फलम्[१२] ॥ दशावर्तं पठेद्धर्मं सप्तम्यां रविवासरे ।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः[१३] ॥ नीरोगो यः पठेद्धर्मं
दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः[१४] ॥
भक्त्या यः प्रपठेद्देवि कवचं प्रत्यहं प्रिये । इह लोके सुखं
भुक्त्वा देहान्ते मुक्तिमाप्नुयात्[१५] ॥ इतिश्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
वज्रपञ्जराख्यं सूर्यकवचम् ॥ श्रीकृष्णार्पणमस्तु ॥

१० कर्मकाण्डपुस्तकं नं. १ (संवत्सरिकपितृक्रियोपयोगि) ।।।=)

११ कर्मकाण्डपुस्तकं नं. २ (नं० १ तथा साष्टकश्राद्ध-गाय-
त्रीब्राह्मण-श्राद्धब्राह्मण-पूयमानब्राह्मण-रुचिस्तवपावमा-
नीकूष्मण्डादिविषयैरलंकृतं विस्तीर्णतया स्फुटं कलशरे-
खोल्लसितं च .... १।)

१२ कर्मकाण्डपुस्तकं नं. ३ (विष्णुबलिविधानादियुतं)
मुद्रणावस्थायां वर्तते ... ... १।)

१३ वेदकल्पद्रुमः (हवनक्रियोपयोगी तथा चातुर्मास्योद्या-
पनविधि-मूलगण्डान्तशान्ति-ग्रहशान्ति-अभिषेकमन्त्र-
कलशग्रहयोरुत्पत्तिस्तयोः स्थापनविधिश्च-ग्रहबलिवि-
धानं-ग्रहक्षमापन-शकुंप्रतिष्ठा-वेश्मप्रतिष्ठा-पञ्चगव्यवि-
धि-तुलादानकन्यासंस्काराद्यात्मकः) ... ... १।)

१४ मेखलापुस्तकम् (ऋचक-विवाहपद्धति-उपनयनपद्धति
"चतुर्विंशतिसंस्कारात्मक" अग्निकुण्डपूजा-कन्यासं-
स्कारनान्दीमुखश्राद्ध-इहकीलिपूजाद्यात्मकम्) ... १।।)

१५ वटुकपूजा(कलशस्थापन-वैश्वदेव-व्याहृत्यादियुता का-
श्मीरिकानां गृहस्थाश्रमस्थितानां धार्मिकाणां शिवरात्रि-
दिनेवागूरद्वादशी-त्रयोदशीपूजादियुता)अतीवोपयोगिनी ।=)

१६ पार्थिवेश्वरपूजा (कलशस्थापन-वैश्वदेवव्याहृत्यादियुता
शिवोपासकानामतीवोपयोगिनी) ... ... ।=)

१७ उपदेशपञ्चकम् (शङ्करस्वामिविरचितं-रत्नप्रभाटीकया
चालङ्कृतम् सम्पूर्णवासिष्ठाशयगर्भं उपनिषत्सारभूतं
अतीवोपयोगि-मुमुक्षूणाम्) ... ... ≡)

१८ योगवासिष्ठसारः (मूलमात्रम्) ... ... ≡)

१९ भक्तिविवेकसारः (अज्ञानबोधिनी-सटीकाभिः प्रह्लाद-

Printed by Ramchandra Yesu Shedge, at the Nirṇaya Sagar Press, 26–28, Kolbhat Lane, Bombay 2.

Published by Keshavbhatta, Patha Shala Teacher, at Nonar, Post Mahashabibhag, Srinagar, Kashmir.

धार्मिकसज्जनोपयोगिनी

श्रीमद्भिर्द्विजोत्तमैः यच्छजाति उपहितैः,

'पण्डितबुधभायू' इति संज्ञया प्रसिद्धैर्महात्मभिः

सहायितेन

पण्डितकेशवभट्टज्योतिर्विदा

संस्कृता—शोधिता च

इयम्

श्रीइन्द्राक्षीयुता

श्रीभवानीनामसहस्रस्तुतिः

मुम्बय्यां

निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा

श्रीसप्तर्षिसंवत्सरे ५००५ विक्रमवत्सरे १९८६

ईसीहायने १९२९

परोपकाराय प्राकाश्यं नीता ।

मूल्यं ।=) आणकपञ्चकम् ।

Printed by Ramchandra Yesu Shedge, Nirnaya-sagar Press,
26-28, Kolbhat Lane, Bombay.

Published by Keshavbhatta, Patha Shala Teacher, at Rainawari,
Bag-Jogi-Lankar, Srinagar, Kashmir.

ॐ अथ भवानीनामसहस्रस्तोत्रम् ।

नामावली च ॥

ॐनमो भवान्यै ॥ अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलकतर्जनीं दधाना । भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ ॥ ॐशङ्खत्रिशूलशरचापकरां त्रिनेत्रां तिग्मेतरांशुकलया विकसत्किरीटाम् । सिंहस्थितामसुरसिद्धनुतां च दुर्गां दूर्वानिभां दुरितदुःखहरां नमामि ॥ ॥ अकुलकुलपतन्ती चक्रमध्ये स्फुरन्ती । मधुरमधुपिबन्ती कण्टकान्भक्षयन्ती । दुरितमपहरन्ती साधकान्पोषयन्ती । जयति जगति देवी सुन्दरी क्रीडयन्ती ॥ ॥ चतुर्भुजामेकवक्त्रां पूर्णेन्दुवदनप्रभाम् । खड्गशक्तिधरां देवीं वरदाभयपाणिकाम् ॥ प्रेतसंस्थां महारौद्रीं भुजगेनोपवीतिनीम् । भवानीं कालसंहारबद्धमुद्राविभूषिताम् ॥ जगत्स्थितिकरीं ब्रह्मविष्णुरुद्रादिभिः सुरैः । स्तुतां तां परमेशानीं नौम्यहं विघ्नहारिणीम् ॥ ॥ ॐनमो भवान्यै ॥ कैलासशिखरे रम्ये देवदेवं महेश्वरम् । ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् । प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ ॥ श्रीनन्दिकेश्वर उवाच ॥ ॥ देवदेव जगन्नाथ संशयोस्ति महान्मम । रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तिवत्सलम् ॥ देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् । पठ्यतेऽविरतं नाथ! त्वत्तः किमपरः परः ॥ इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः ।

प्रोवाच भगवानेको विकसन्नेत्रपङ्कजः ॥ ॥ श्रीभगवानुवाच ॥ साधु साधु गणश्रेष्ठ पृष्टवानसि मां च यत् । स्कन्दस्यापि च यद्गोप्यं रहस्यं कथयामि तत् ॥ पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतना । गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥ तस्यामहं समुत्पन्नस्तत्वैस्तैर्महदादिभिः । चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तस्थुषी । हेतुः सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा ॥ इच्छेति परमा शक्तिरुन्मिमील ततः परम् । ततो वागिति विख्याता शक्तिः शब्दमयी परा ॥ प्रादुरासीज्जगन्माता वेदमाता सरस्वती । ब्राह्मी च वैष्णवी रौद्री कौमारी पार्वती शिवा ॥ सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥ तयैतत्सृज्यते विश्वमनाधारं च धार्यते ॥ तयैतत्पाल्यते सर्वं तस्यामेव प्रलीयते । अर्चिता प्रणता ध्याता सर्वभावविनिश्चिता ॥ आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी । तस्या अनुग्रहादेव तामेव स्तुतवानहम् ॥ सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः । स्तवेनानेन सन्तुष्टा मामेव प्रविवेश सा ॥ तदारभ्य मया प्राप्तमैश्वर्यं पदमुत्तमम् । तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम् ॥ ससुरासुरगन्धर्वयक्षराक्षसमानवम् । सपन्नगं ससमुद्रं सशैलवनकाननम् ॥ सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम् । नन्दिन्नामसहस्रेण स्तवेनानेन सर्वदा ॥ स्तुवे परापरां शक्तिं ममानुग्रहकारिणीम् । इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम् । प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥ ॥ श्रीनन्दिकेश्वर उवाच ॥ ॥ भगवन्देवदेवेश लोकनाथ जगत्पते । भक्तोसि तव दासोस्मि प्रसादः क्रियतां मयि । देव्याः स्तवमिमं पुण्यं दुर्लभं यत्सुरै-

रपि । श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु ॥ ॥ श्रीभगवानुवाच ॥ ॥ शृणु नन्दिन्महाभाग स्तवराजमिमं शुभम् । सहस्रैर्नामभिर्दिव्यैः सिद्धिदं सुखमोक्षदम् । शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः । त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तवः ॥ ॥ अस्य श्रीभवानीनामसहस्रस्तवराजस्य, महादेवऋषिः, अनुष्टुप्छन्दः, आद्या शक्तिः, भगवती भवानी देवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं, अमुककामनासिद्ध्यर्थे पाठे होमे वा विनियोगः ॥ अथ करन्यासः ॥ ॐ एकवीरायै अङ्गुष्ठाभ्यां नमः ॐ महामायायै तर्जनीभ्यां नमः, ॐ पार्वत्यै मध्यमाभ्यां नमः ॐ गिरिशप्रियायै अनामिकाभ्यांनमः, ॐ गौर्यै कनिष्ठिकाभ्यां नमः, करालिन्यै करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ षडङ्गन्यासः ॥ ॐ एकवीरायै हृदयायनमः, ॐ महामायायै शिरसे स्वाहा, ॐ पार्वत्यै शिखायै वषट्, ॐ गिरिशप्रियायै कवचायहुम्, ॐ गौर्यै नेत्रत्रयाय वौषट्, ॐ करालिन्यै अस्त्रायफट् ॥ प्राणायामः ॥ ॥ ध्यानम् ॥ बालार्कमण्डलाभासं चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ १ ॥ अर्धेन्दुमौलिममलाममराभिवन्द्यामम्भोजपाशसृणिरक्तकपालहस्ताम् । रक्ताङ्गरागरशनाभरणां त्रिनेत्रां ध्याये शिवस्य वनितां मधुविह्वलाङ्गीम् ॥ ॥ बीजत्रयाय विद्महे तत्प्रधानाय धीमहि, तन्नः शक्तिः प्रचोदयात् ॥ २ ॥ मूलम् । " ॐश्रींश्रींॐॐह्रींश्रींश्रीं भवानि हुं फट् स्वाहा " ॥ १०८ ॥

॥ श्रीईश्वर उवाच ॥

ॐमहाविद्या जगन्माता महालक्ष्मीः शिवप्रिया । विष्णुमाया शुभा शान्ता सिद्धा सिद्धसरस्वती । क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला । हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया । त्रिपुरानन्दिनी नन्दा सुनन्दा सुरवन्दिता । यज्ञविद्या महामाया वेदमाता सुधाधृतिः । प्रीतिप्रिया प्रसिद्धा च मृडानी विन्ध्यवासिनी । सिद्धविद्या महाशक्तिः पृथ्वी नारदसेविता । पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना । प्रह्लादिनी महामाता दुर्गा दुर्ग-

ॐ महाविद्यायैस्वाहा, जगन्मात्रे, महालक्ष्म्यै, शिवप्रियायै, विष्णुमायायै, शुभायै, शान्तायै, सिद्धायै, सिद्धसरस्वत्यै, क्षमायै, कान्त्यै, प्रभायै, ज्योत्स्नायै, पार्वत्यै, सर्वमङ्गलायै, हिङ्गुलायै, चण्डिकायै, दान्तायै, पद्मायै, लक्ष्म्यै, हरिप्रियायै, त्रिपुरानन्दिन्यै, नन्दायै, सुनन्दायै, सुरवन्दितायै, यज्ञविद्यायै, महामायायै, वेदमात्रे, सुधाधृत्यै, प्रीतिप्रियायै, प्रसिद्धायै, मृडान्यै, विन्ध्यवासिन्यै, सिद्धविद्यायै, महाशक्त्यै, पृथ्व्यै, नारदसेवितायै, पुरुहूतप्रियायै, कान्तायै, कामिन्यै, पद्मलोचनायै, प्रह्लादिन्यै, महामात्रे, दुर्गायै, दुर्गतिना-

तिनाशिनी । ज्वालामुखी सुगोत्रा च ज्योतिः कुमुद्हासिनी । दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी । अपर्णा शाम्बरी माया मदिरा मृदुहासिनी । कुलवागीश्वरी नित्यानित्यक्लिन्ना कृशोदरी । कामेश्वरी च नीला च भीरुण्डा वह्निवासिनी । लम्बोदरी महाकाली विद्याविद्येश्वरी तथा । नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी । सङ्कर्षणी नारसिंही वैष्णवी च महोदरी । कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी । नारायणी महानिद्रा योगनिद्रा प्रभावती । प्रज्ञापारमिता प्रज्ञा

शिन्यै, ज्वालामुख्यै सुगोत्रायै, ज्योतिषे, कुमुद्हासिन्यै, दुर्गमायै, दुर्लभायै, विद्यायै, स्वर्गतये, पुरवासिन्यै, अपर्णायै, शाम्बरीमायायै, मदिरायै, मृदुहासिन्यै, कुलवागीश्वर्यै, नित्यानित्यक्लिन्नायै, कृशोदर्यै, कामेश्वर्यै, नीलायै, भीरुण्डायै, वह्निवासिन्यै, लम्बोदर्यै, महाकाल्यै, विद्याविद्येश्वर्यै, नरेश्वर्यै, सत्यायै, सर्वसौभाग्यवर्धिन्यै, सङ्कर्षण्यै, नारसिंह्यै, वैष्णव्यै, महोदर्यै, कात्यायन्यै, चम्पायै, सर्वसम्पत्तिकारिण्यै, नारायण्यै, महानिद्रायै, योगनिद्रायै, प्रभावत्यै, प्रज्ञापारमितायै, प्रज्ञायै, तारायै, मधुमत्यै, मधवे, क्षीरार्णवसुतायै, हालायै, कालिकायै, सिंहवाहनायै, ॐकारायै, सु-

तारा मधुमती मधु । क्षीरार्णवसुता हाला कालिका सिंहवाहना । ॐकारा च सुधाहारा चेतना कोपना कृतिः । अर्धबिन्दुधरा धीरा विश्वमाता कलावती १०० । पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती । कुण्डासना जगद्धात्री बुद्धमाता जिनेश्वरी । जिनमाता जिनेन्द्रा च शारदा हंसवाहना । राज्यलक्ष्मीर्वषट्कारा सुधाकारासुधात्मिका । राजनीतिस्त्रयीवार्ता दण्डनीतिः क्रियावती । सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्परायणा । सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती । गोदावरी विपाशा च कावेरी च शतद्रुका ।

धाहारायै, चेतनायै, कोपनायै, कृत्यै, अर्धबिन्दुधरायै, धीरायै विश्वमात्रे, "तेजोऽसि" कलावत्यै, १०० ध्यानम् । वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरीं ताम् ॥ ॐपद्मावत्यैस्वाहा, सुवस्त्रायै, प्रबुद्धायै, सरस्वत्यै, कुण्डासनायै, जगद्धात्र्यै, बुद्धमात्रे, जिनेश्वर्यै, जिनमात्रे, जिनेन्द्रायै, शारदायै, हंसवाहनायै, राज्यलक्ष्म्यै, वषट्कारायै, सुधाकारायै, सुधात्मिकायै, राजनीत्यै, त्रयीवार्तायै, दण्डनीत्यै, क्रियावत्यै, सद्भूतये, तारिण्यै, श्रद्धायै, सद्गतये, सत्परायणायै, सिन्धवे, मन्दाकिन्यै, गङ्गायै, यमुनायै सरस्वत्यै, गोदावर्यै, विपाशायै, कावेर्यै, शतह्रदायै, सरय्वै, चन्द्रभागायै,

सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः। नर्मदा कर्मनाशा च चर्मण्वत्यथ देविका। वेत्रवती वितस्ता च वरदा नरवाहना। सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी । एकचक्षुः सहस्राक्षी सुश्रेणिर्भगमालिनी । सेनाश्रेणिः पताका च सुव्यूहा युद्धकाङ्क्षिणी । पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया । परापरकलाकान्ता त्रिशक्तिर्मोक्षदायिनी। ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कुलवासिनी। इच्छा भगवती शक्तिः कामधेनुः कृपावती । वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा। गौरी

कौशिक्यै, गण्डक्यै, शुचये, नर्मदायै, कर्मनाशायै, चर्मण्वत्यै, देविकायै, वेत्रवत्यै, वितस्तायै, वरदायै, नरवाहनायै, सत्यै, पतिव्रतायै, साध्व्यै,सुचक्षुषे, कुण्डवासिन्यै, एकचक्षुषे, सहस्राक्ष्यै, सुश्रेणये, भगमालिन्यै, सेनाश्रेणये, पताकायै, सुव्यूहायै, युद्धकाङ्क्षिण्यै, पताकिन्यै, दयारम्भायै, विपञ्च्यै, पञ्चमप्रियायै, परापरकलाकान्तायै, त्रिशक्तये, मोक्षदायिन्यै, ऐन्द्र्यै, माहेश्वर्यै, ब्राह्म्यै, कौमार्यै, कुलवासिन्यै, इच्छायै, भगवत्यै, शक्तये, कामधेनवे, कृपावत्यै, वज्रायुधायै, वज्रहस्तायै, चण्ड्यै, चण्डपराक्रमायै, गौर्यै, सुवर्णवर्णायै, स्थितिसंहारकारिण्यै, एकानेकायै, महेज्यायै, शतबाहवे, महाभुजायै, भुजङ्गभूषणायै,

सुवर्णवर्णा च स्थिति-
संहारकारिणी । एका-
नेका महेज्या च शत-
बाहुर्महाभुजा । भुज-
ङ्गभूषणा भूषा षट्चक्र-
क्रमवासिनी । षट्चक्र-
भेदिनी शूरा कायस्था
कायवर्जिता । सुस्मि-
ता सुमुखी क्षामा मू-
लप्रकृतिरीश्वरी । २००
अजा च बहुवर्णा च
पुरुषार्थप्रवर्तिनी । र-
क्ता नीला सिता श्या-
मा कृष्णा पीता च
कर्बुरा । क्षुधा तृष्णा
जरा वृद्धा तरुणी क-
रुणालया । कला काष्ठा
मुहूर्ता च निमेषा का-
लरूपिणी । सुवर्णर-
सनानासा चक्षुःस्पर्श-
वती रसा । गन्धप्रिया
सुगन्धा च सुस्पर्शा च
मनोगतिः । मृगना-
भिर्मृगाक्षी च कर्पूरा-

भूषायै, षट्चक्रक्रमवासिन्यै,
षट्चक्रभेदिन्यै, शूरायै, काय-
स्थायै, कायवर्जितायै, सु-
स्मितायै, सुमुख्यै, क्षामायै,
मूलप्रकृतये, "तेजोसि" ईश्वर्यै,
"२०० माता भवानी च
पिता भवानी बन्धुर्भवानी च
गुरुर्भवानी । विद्या भवानी
द्रविणं भवानी यतो यतो
यामि ततो भवानी ॥" ॐ-
अजायैस्वाहा, बहुवर्णायै, पु-
रुषार्थप्रवर्तिन्यै, रक्तायै, नी-
लायै, सितायै, श्यामायै,
कृष्णायै, पीतायै, कर्बुरायै,
क्षुधायै, तृष्णायै, जरायै, वृ-
द्धायै, तरुण्यै, करुणालयायै,
कलायै, काष्ठायै, मुहूर्तायै,
निमेषायै, कालरूपिण्यै, सुव-
र्णरसनानासायै, चक्षुःस्पर्श-
वत्यै, रसायै, गन्धप्रियायै,
सुगन्धायै, सुस्पर्शायै, मनो-
गतये, मृगनाभये, मृगाक्ष्यै,
कर्पूरामोदधारिण्यै, पद्मयो-

मोदधारिणी । पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी । योनिमुद्रा महामुद्रा खेचरी खगगामिनी । मधुश्रीर्माधवीवल्ली मधुमत्ता मदोद्धता । मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी । रक्ताम्बरधरा क्षीबा रक्तपुष्पावतंसिनी । शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया । सुवेणी पद्महस्ता च मुक्ताहारविभूषणा । कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा । खड्गिनी चक्रहस्ता च भुसुण्डी परिघायुधा । चापिनी पाशहस्ता च त्रिशूलवरधारिणी । सुबाणा शक्तिहस्ता च मयूरवरवाहना । वरायुधधरा वीरा वीरपा-

नयै, सुकेश्यै, सुलिङ्गायै, भगरूपिण्यै, योनिमुद्रायै, महामुद्रायै, खेचर्यै, खगगामिन्यै, मधुश्रियै, माधवीवल्ल्यै, मधुमत्तायै, मदोद्धतायै, मातङ्ग्यै, शुकहस्तायै, पुष्पबाणायै, इक्षुचापिन्यै, रक्ताम्बरधरायै, क्षीबायै, रक्तपुष्पावतंसिन्यै, शुभ्राम्बरधरायै, धीरायै, महाश्वेतायै, वसुप्रियायै, सुवेण्यै, पद्महस्तायै, मुक्ताहारविभूषणायै, कर्पूरामोदनिःश्वासायै, पद्मिन्यै, पद्ममन्दिरायै, खड्गिन्यै, चक्रहस्तायै, भुसुण्ड्यै, परिघायुधायै, चापिन्यै, पाशहस्तायै, त्रिशूलवरधारिण्यै, सुबाणायै, शक्तिहस्तायै, मयूरवरवाहनायै, वरायुधधरायै, वीरायै, वीरपानमदोत्कटायै, वसुधायै, वसुधारायै, जयायै, शाकम्भर्यै, शिवायै, विजयायै,

नमदोत्कटा । वसुधा वसुधारा च जया शाकम्भरी शिवा । विजया च जयन्ती च सुस्तनी शत्रुनाशिनी । अन्तर्वत्नी वेदशक्तिर्वरदा वरधारिणी । शीतला च सुशीला च बालग्रहविनाशिनी । कुमारी वसुपर्णा च कामाख्या कामवन्दिता । जालन्धरधराऽनन्ता कामरूपनिवासिनी । कामबीजवती सत्या सत्यधर्मपरायणा । स्थूलमार्गस्थिता "३००" सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी । षट्कोणा च त्रिकोणा च त्रिनेत्रा वृषभध्वजा । वृषप्रिया वृषारूढा महिषासुरघातिनी । सुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा । क-

जयन्त्यै, सुस्तन्यै, शत्रुनाशिन्यै, अन्तर्वत्न्यै, वेदशक्त्यै, वरदायै, वरधारिण्यै, शीतलायै, सुशीलायै, बालग्रहविनाशिन्यै, कुमार्यै, वसुपर्णायै, कामाख्यायै, कामवन्दितायै, जालन्धरधरायै, अनन्तायै, कामरूपनिवासिन्यै, कामबीजवत्यै, सत्यायै, सत्यधर्मपरायणायै, "तेजोऽसि" ॐस्थूलमार्गस्थितायैस्वाहा, ॥ २०० ॥ "यावत्पदं पदसरोजयुगं त्वदीयं नाङ्गीकरोति हृदयेषु जगच्छरण्ये । तावद्विकल्पजटिला कुटिलप्रकारास्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥" ॐसूक्ष्मायैस्वाहा, सूक्ष्मबुद्धिप्रबोधिन्यै, षट्कोणायै, त्रिकोणायै, त्रिनेत्रायै, वृषभध्वजायै, वृषप्रियायै, वृषारूढायै, महिषासुरघातिन्यै, सुम्भदर्पहरायै, दीप्तायै, दीप्तपावकसन्निभा-

पालभूषणा काली कपालमालभारिणी । कपालकुण्डला दीर्घा शिवदूती घनध्वनिः। सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी । कम्बुग्रीवा वसुमती च्छत्रच्छायाकृतालया । जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी । प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी । मूलाधारा निराकारा वह्निकुण्डकृतालया । वायुकुण्डसुखासीना निराधारा निराश्रया । श्वासोच्छ्वासगतिर्जीवाग्राहिणी वह्निसंश्रया । वल्लीतन्तुसमुत्थाना षड्रसास्वादलोलुपा । तपस्विनी तपःसिद्धिस्तपसः सिद्धिदायिनी । तपोनिष्ठा

यै, कपालभूषणायै, काल्यै, कपालमालभारिण्यै, कपालकुण्डलायै, दीर्घायै, शिवदूत्यै, घनध्वनये, सिद्धिदायै, बुद्धिदायै, नित्यायै, सत्यमार्गप्रबोधिन्यै, कम्बुग्रीवायै, वसुमत्यै, छत्रच्छायाकृतालयायै, जगद्गर्भायै, कुण्डलिन्यै, भुजगाकारशायिन्यै, प्रोल्लसत्सप्तपद्मायै, नाभिनालमृणालिन्यै, मूलाधारायै, निराकारायै, वह्निकुण्डकृतालयायै, वायुकुण्डसुखासीनायै, निराधारायै, निराश्रयायै, श्वासोच्छ्वासगतये, जीवाग्राहिण्यै, वह्निसंश्रयायै, वल्लीतन्तुसमुत्थानायै, षड्रसास्वादलोलुपायै, तपस्विन्यै, तपःसिद्धये, तपसःसिद्धिदायिन्यै, तपोनिष्ठायै, तपोयुक्तायै, तापस्यै, तपःप्रियायै, सप्तधा-

तपोयुक्ता तापसी च तपःप्रिया । सप्तधातुमयी मूर्तिः सप्तधात्वन्तराश्रया । देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्भुता । ओषधिर्वैद्यमाता च द्रव्यशक्तिः प्रभावती । वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी । मृगया मृगमांसादा मृगत्वङ्मृगलोचना । वागुरा बन्धरूपा च वधरूपा वधोद्भुता । वन्दी वन्दिस्तुताकारा काराबन्धविमोचिनी । शृङ्खला खलहा विद्युद्दृढबन्धविमोचिनी । अम्बिकाऽम्बालिका चाम्बा स्वक्षा साधुजनार्चिता । कौलिकी कुलविद्या च सुकुला कुलपूजिता । कालचक्रभ्रमा भ्रान्ता विभ्रमा भ्रमनाशिनी ।

तुमय्यै, मूर्त्यै, सप्तधात्वन्तराश्रयायै, देहपुष्टये, मनःपुष्टये, अन्नपुष्टये, बलोद्भुतायै, ओषधये, वैद्यमात्रे, द्रव्यशक्तये, प्रभावत्यै, वैद्यायै, वैद्यचिकित्सायै, सुपथ्यायै, रोगनाशिन्यै, मृगयायै, मृगमांसादायै, मृगत्वचे, मृगलोचनायै, वागुरायै, बन्धुरूपायै, वधरूपायै, वधोद्भुतायै, वन्द्यै, वन्दिस्तुतायै, कारायै, काराबन्धविमोचिन्यै, शृङ्खलायै, खलहायै, विद्युते, दृढबन्धविमोचिन्यै, अम्बिकायै, अम्बालिकायै, अम्बायै, स्वक्षायै, साधुजनार्चितायै, कौलिक्यै, कुलविद्यायै, सुकुलायै, कुलपूजितायै, कालचक्रभ्रमायै, भ्रान्तायै, विभ्रमायै, भ्रमनाशिन्यै, वातात्यै, मेघमालायै, सुवृष्ट्यै, सस्यवर्धिन्यै, अकारायै, इकारायै, "तेजोऽसि"

वात्याली मेघमाला च सुवृष्टिः सस्यवर्धिनी। अकारा च इकारा च "४००"।उकारैकाररूपिणी। ह्रींकारीबीजरूपा च क्लींकाराम्बरवासिनी। सर्वाक्षरमयीमूर्तिरक्षरा वर्णमालिनी। सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया। वश्या च वश्यबीजा च लोकवश्यविभाविनी। नृपवश्या नृपसेव्या नृपवश्यकरी प्रिया। महिषी नृपमान्या च नृमान्या नृपनन्दिनी। नृपधर्ममयी धन्या धनधान्यविवर्धिनी। चतुर्वर्णमयी मूर्तिश्चतुर्वर्णैः सुपूजिता। सर्वधर्ममयी सिद्धिश्चतुराश्रमवासिनी। ब्राह्मणी क्षत्रिया वैश्या

ॐउकारायैस्वाहा॥४००॥"तां भवानीं भवानीतक्लेशनाशविशारदाम्। शारदां शरदम्भोजसितपद्मासनां नमः॥"
ॐऐकाररूपिण्यैस्वाहा, ह्रींकारीबीजरूपायै, क्लींकाराम्बरवासिन्यै, सर्वाक्षरमयीमूर्त्यै, अक्षरायै, वर्णमालिन्यै, सिन्दूरारुणवर्णायै, सिन्दूरतिलकप्रियायै, वश्यायै, वश्यबीजायै, लोकवश्यविभाविन्यै, नृपवश्यायै, नृपसेव्यायै, नृपवश्यकर्यै, प्रियायै, महिष्यै, नृपमान्यायै, नृमान्यायै, नृपनन्दिन्यै, नृपधर्ममय्यै, धन्यायै, धनधान्यविवर्धिन्यै, चतुर्वर्णमयीमूर्त्यै, चतुर्वर्णैःसुपूजितायै, सर्वधर्ममयीसिद्ध्यै, चतुराश्रमवासिन्यै, ब्राह्मण्यै, क्षत्रियायै, वैश्यायै, शूद्रायै, अवरवर्ण-

शूद्रा चावरवर्णजा । वेदमार्गरता यज्ञा वेदविश्वविभाविनी । अस्त्रशस्त्रमयीविद्या वरशस्त्रास्त्रधारिणी । सुमेधा सत्यमेधा च भद्रकाल्यऽपराजिता। गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया । त्रिसन्ध्या त्रिपदा धात्री सुपर्वा सामगायनी । पञ्चाली बालिका बाला बालक्रीडा सनातनी । गर्भाधारधरा शून्या गर्भाशयनिवासिनी । सुरारिघातिनी कृत्या पूतना च तिलोत्तमा। लज्जा रसवती नन्दा भवानी पापनाशिनी। पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानलोचना । सप्तसुरमयी तन्त्री षड्जमध्यमदैवता। मूर्छा-

जायै, वेदमार्गरतायै, यज्ञायै, वेदविश्वविभाविन्यै, अस्त्रशस्त्रमयीविद्यायै, वरशस्त्रास्त्रधारिण्यै, सुमेधायै, सत्यमेधायै, भद्रकाल्यै, अपराजितायै, गायत्र्यै, सत्कृतये, सन्ध्यायै, सावित्र्यै, त्रिपदाश्रयायै, त्रिसन्ध्यायै, त्रिपदायै, धात्र्यै, सुपर्वायै, सामगायिन्यै, पञ्चाल्यै, बालिकायै, बालायै, बालक्रीडायै, सनातन्यै, गर्भाधारधरायै, शून्यायै, गर्भाशयनिवासिन्यै, सुरारिघातिन्यै, कृत्यायै, पूतनायै, तिलोत्तमायै, लज्जायै, रसवत्यै, नन्दायै, भवान्यै, पापनाशिन्यै, पट्टाम्बरधरायै, गीत्यै, सुगीत्यै, ज्ञानलोचनायै, सप्तसुरमय्यै, तन्त्र्यै, षड्जमध्यमदैवतायै, मूर्च्छानायै, ग्रामसंस्थानायै, स्वच्छस्वस्थानवासिन्यै, अट्टाट्टहासिन्यै, प्रेतायै, प्रेतासननिवासिन्यै,

ना ग्रामसंस्थाना स्वच्छस्वस्थानवासिनी । अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी । गीतनृत्तप्रिया कामा तुष्टिदा पुष्टिदा क्षया । निष्ठा सत्यप्रिया प्रख्या लोकेशी च सुरोत्तमा । सुविषा ज्वालिनीज्वाला विषमोहार्त्तिनाशिनी । विषारिर्नागदमनी कुरुकुल्लाऽमृतोद्भवा । भूतभीतिहरा रक्षा "५००" भूतावेशविनाशिनी । रक्षोघ्नी राक्षसीरात्रिर्दीर्घनिद्रा दिवागतिः । चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी । डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी । सितासितप्रि-

गीतनृत्तप्रियायै, कामायै, तुष्टिदायै, पुष्टिदायै, अक्षयायै, निष्ठायै,सत्यप्रियायै, प्रख्यायै, लोकेश्यै, सुरोत्तमायै, सुविषायै, ज्वालिन्यै, ज्वालायै, विषमोहार्तिनाशिन्यै, विषायै,नागदमन्यै,कुरुकुल्लायै,अमृतोद्भवायै, भूतभीतिहरायै, "तेजोऽसि" ॐ रक्षायैस्वाहा, ५०० "भवानि त्वं दासे मयि वितर दृष्टिं सकरुणामिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥" ॐभूतावेशविनाशिन्यैस्वाहा, रक्षोघ्न्यै, राक्षस्यै, रात्र्यै, दीर्घनिद्रायै, दिवागतये,चन्द्रिकायै, चन्द्रकान्तये, सूर्यकान्तये, निशाचर्यै, डाकिन्यै, शाकिन्यै शिष्यायै, हाकिन्यै, चक्रवाकि-

या स्वङ्गा सुकुला वनदेवता । गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा । महामारी विनिन्द्रा च तन्द्रा मृत्युविनाशिनी । चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी । अणिमादिगुणोपेता सुस्पृहा कामरूपिणी । अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी । अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी । चतुःसमुद्रशयना चतुर्वर्गफलप्रदा । काशपुष्पप्रतीकाशा शरत्कुमुदलोचना । भूता भव्या भविष्या च शैलजा शैलवासिनी । वाममार्गरता वामा शिववामाङ्गवासिनी । वामाचारप्रिया तुष्टिर्लोपामुद्राप्रबोधिनी ।

न्यै, सितासितप्रियायै, स्वङ्गायै, सुकुलायै, वनदेवतायै, गुरुरूपधरायै, गुर्व्यै, मृत्यवे, मार्यै, विशारदायै, महामार्यै, विनिन्द्रायै, तन्द्रायै, मृत्युविनाशिन्यै, चन्द्रमण्डलसङ्काशायै, चन्द्रमण्डलवासिन्यै, अणिमादिगुणोपेतायै, सुस्पृहायै, कामरूपिण्यै, अष्टसिद्धिप्रदायै, प्रौढायै, दुष्टदानवघातिन्यै, अनादिनिधनायै, पुष्टये, चतुर्बाहवे, चतुर्मुख्यै, चतुःसमुद्रशयनायै, चतुर्वर्गफलप्रदायै, काशपुष्पप्रतीकाशायै, शरत्कुमुदलोचनायै, भूतायै, भव्यायै, भविष्यायै, शैलजायै, शैलवासिन्यै, वाममार्गरतायै, वामायै, शिववामाङ्गवासिन्यै, वामाचारप्रियायै, तुष्टये, लोपामुद्राप्रबोधिन्यै, भूतात्मने, परमा-

भूतात्मा परमात्मा च भूतभव्यविभाविनी । मङ्गला साधुशीला च परमार्थप्रबोधिका । दक्षिणा दक्षिणामूर्तिः सुदक्षिणा हरिप्रसूः । योगिनी योगियुक्ता च योगाङ्गा ध्यानशालिनी । योगपट्टधरा मुक्ता मुक्तानां परमागतिः । नारसिंही सुजन्मा च त्रिवर्गफलदायिनी । धर्मदा धनदा चैका कामदा मोक्षदा द्युतिः । साक्षिणी क्षणदा दक्षा दक्षजा कोटिरूपिणी । क्रतुः कात्यायनी स्वच्छा स्वच्छन्दा च कविप्रिया । सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा । मेनापुत्री सतीमाता मैनाकभगिनी तडित् । सौदामिनी

त्मने, भूतभव्यविभाविन्यै, मङ्गलायै, साधुशीलायै, परमार्थप्रबोधिकायै, दक्षिणायै, दक्षिणामूर्तये, सुदक्षिणायै, हरिप्रस्वै, योगिन्यै, योगयुक्तायै, योगाङ्गायै, ध्यानशालिन्यै, योगपट्टधरायै, मुक्तायै, मुक्तानांपरमागतये, नारसिंह्यै, सुजन्मने, त्रिवर्गफलदायिन्यै, धर्मदायै, धनदायै, एकायै, कामदायै, मोक्षदायै, द्युतये, साक्षिण्यै, क्षणदायै, दक्षायै, दक्षजायै, कोटिरूपिण्यै, क्रतवे कात्यायन्यै, स्वच्छायै, स्वच्छन्दायै, कविप्रियायै, सत्यागमायै, बहिःस्थायै, काव्यशक्तये, कवित्वदायै, मेनापुत्र्यै, सतीमात्रे, मैनाकभगिन्यै, तडिते "तेजोऽसि" ॐ सौदामिन्यैस्वाहा ६०० । "किं किं दुःखं दनुजदलनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न

सुदामा च सुधामा धामशालिनी । सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवार्धिनी । श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी । रक्तबीजवधोद्दृप्ता सुतन्तुर्बीजसन्ततिः । जगज्जीवा जगद्बीजा जगत्त्रयहितैषिणी । चामीकररुचिश्चान्द्री साक्षया षोडशीकला यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता । चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी । चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्धुरा । अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी । अमा कलशहस्ता च पूर्णकुम्भपयोधरा । अभीरुर्भैरवी भीरा भीमा त्रिपुरभैरवी । महा-

स्तुतायाम् । का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम्" ॥ सुदामायै स्वाहा, सुधामायै, धामशालिन्यै, सौभाग्यदायिन्यै, दिवे, सुभगायै, द्युतिवर्धिन्यै, श्रीकृत्तिवसनायै, कङ्काल्यै, कलिनाशिन्यै, रक्तबीजवधोद्दृप्तायै, सुतन्तवे, बीजसन्ततये, जगज्जीवायै, जगद्बीजायै, जगत्त्रयहितैषिण्यै, चामीकररुचये चान्द्र्यै, साक्षयायै, षोडशीकलायै, यत्तत्पदानुबन्धायै, यक्षिण्यै, धनदार्चितायै, चित्रिण्यै, चित्रमायायै, विचित्रायै, भुवनेश्वर्यै, चामुण्डायै, मुण्डहस्तायै, चण्डमुण्डवधोद्धुरायै, अष्टम्यै, एकादश्यै, पूर्णायै, नवम्यै, चतुर्दश्यै, अमायै, कलशहस्तायै, पूर्णकुम्भपयोधरायै, अभीरवे, भैरव्यै, भीरायै, भीमायै, त्रिपुरभै-

रुण्डा च रौद्री च महाभैरवपूजिता । निर्मुण्डा हस्तिनी चण्डा करालदशनानना । कराला विकराला च घोरा घुर्घुरनादिनी । रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा । कादम्बरी पटासा च काश्मीरी कुङ्कुमप्रिया । क्षान्तिर्बहुसुवर्णा च मतिर्बहुसुवर्णदा । मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी । हिंसा हंसगतिर्हंसी हंसोज्ज्वलशिरोरुहा । पूर्णचन्द्रमुखी श्यामा स्मितास्या श्यामकुन्तला । मषी च लेखनी लेखा सुलेखा लेखकप्रिया । शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता । कुरुक्षेत्रावनिः काशी मथुरा काञ्च्यवन्ति-

रुण्ड्यै, महारुण्डायै, रौद्र्यै, महाभैरवपूजितायै, निर्मुण्डायै, हस्तिन्यै, चण्डायै, करालदशनाननायै, करालायै, विकरालायै, घोरायै, घुर्घुरनादिन्यै, रक्तदन्तायै, ऊर्ध्वकेश्यै, बन्धूककुसुमारुणायै, कादम्बर्यै, पटासायै, काश्मीर्यै, कुङ्कुमप्रियायै, क्षान्तये, बहुसुवर्णायै, मतये, बहुसुवर्णदायै, मातङ्गिन्यै, वरारोहायै, मत्तमातङ्गगामिन्यै, हिंसायै, हंसगतये, हंस्यै, हंसोज्ज्वलशिरोरुहायै, पूर्णचन्द्रमुख्यै, श्यामायै, स्मितास्यायै, श्यामकुन्तलायै, मष्यै, लेखन्यै, लेखायै, सुलेखायै, लेखकप्रियायै, शङ्खिन्यै, शङ्खहस्तायै, जलस्थायै, जलदेवतायै, कुरुक्षेत्रावनये, काश्यै, मथुरायै, काञ्च्यै, अवन्तिका-

का । अयोध्या द्वारिकामाया तीर्था तीर्थकरप्रिया । त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी । कौशिकी तु कुशावर्ता ॥ ७०० ॥ कोशाम्बी कोशवर्धिनी । कोशदा पद्मकोशाक्षी कुसुम्भकुसुमप्रिया । तोतुला च तुलाकोटिः कोटिस्था कोटराश्रया । स्वयम्भूश्च सुगुप्ता च सुरूपा रूपवर्धिनी । तेजस्विनी सुभिक्षा च बलदा बलदायिनी । महाकोशी महावर्त्ता बुद्धिः सदसदात्मिका । महाग्रहहरा सौम्या विशोका शोकनाशिनी । सात्त्विकी सत्त्वसंस्था

यै, अयोध्यायै, द्वारिकामायायै, तीर्थायै, तीर्थकरप्रियायै, त्रिपुष्करायै, अप्रमेयायै, कोशस्थायै, कोशवासिन्यै, कौशिक्यै, "तेजोऽसि" ओंकुशावर्तायैस्वाहा, ७००

आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुःसायकैर्विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वराणाम् ॥ ॐकोशाम्ब्यैस्वाहा, कोशवर्धिन्यै, कोशदायै, पद्मकोशाक्ष्यै, कुसुम्भकुसुमप्रियायै, तोतुलायै, तुलाकोटये, कोटिस्थायै, कोटराश्रयायै, स्वयम्भुवे, सुगुप्तायै, सुरूपायै, रूपवर्धिन्यै, तेजस्विन्यै, सुभिक्षायै, बलदायै, बलदायिन्यै, महाकोश्यै, महावर्तायै, बुद्ध्यै, सदसदात्मिकायै, महाग्रहहरायै,

च राजसी च रजोवृता । तामसी च तमोयुक्ता गुणत्रयविभाविनी । अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी । शम्भुकल्याणिनी कल्पा मनःसङ्कल्पसन्ततिः । सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा । सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिनी । जाग्रती च सुषुप्तिश्च स्वप्नावस्था तुरीयका । त्वरा मन्दगतिर्मन्दा मदिरामोदधारिणी । पानभूमिः पानपात्रा पानदानकरोद्यता । अघूर्णारुणनेत्रा च किञ्चिदव्यक्तभाषिणी । आशापूरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ ६० ॥ नागवल्ली नागकन्या भोगिनी भोगवल्लभा । सर्वशास्त्रवती विद्या सुस्मृति-

सौम्यायै, विशोकायै, शोकनाशिन्यै, सात्त्विक्यै, सत्त्वसंस्थायै, राजस्यै, रजोवृतायै, तामस्यै, तमोयुक्तायै, गुणत्रयविभाविन्यै, अव्यक्तायै, व्यक्तरूपायै, वेदविद्यायै, शाम्भव्यै, शम्भुकल्याणिन्यै, कल्पायै, मनःसङ्कल्पसन्तत्यै, सर्वलोकमयीशक्तये ४० सर्वश्रवणगोचरायै, सर्वज्ञानवत्यै, वाञ्छायै, सर्वतत्त्वावबोधिन्यै, जाग्रत्यै, सुषुप्तये, स्वप्नावस्थायै, तुरीयकायै, त्वरायै, मन्दगतये, मन्दायै, मदिरामोदधारिण्यै, पानभूमये, पानपात्रायै, पानदानकरोद्यतायै, अघूर्णारुणनेत्रायै, किञ्चिदव्यक्तभाषिण्यै, आशापूरायै, दीक्षायै, दक्षायै, दीक्षितपूजितायै, नागवल्ल्यै, नागकन्यायै, भोगिन्यै, भोगवल्लभायै, सर्वशास्त्रवतीविद्यायै, सुस्मृतये, धर्मवादिन्यै,

धर्मवादिनी । श्रुतिः श्रुतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी । मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला। सुनाभिर्यातना जातिर्गम्भीराऽभाववर्जिता। नागपाशधरा मूर्तिरगाधा नागकुण्डला। सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी । सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः । मधुस्रवा स्रवन्ती च भ्रामरी भ्रमरालका । मातृमण्डलमध्यस्था मातृमण्डलवासिनी । कुमारजननी क्रूरा सुमुखी ज्वरनाशिनी । अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ८०० ॥ सर्वसौख्यवती युक्तिराहारपरिणामिनी । निधानं पञ्चभूतानां भवसागर-

श्रुतये, श्रुतिधरायै, ज्येष्ठायै, श्रेष्ठायै, पातालवासिन्यै, मीमांसायै, तर्कविद्यायै, ७५ सुभक्तये, भक्तवत्सलायै, सुनाभये, यातनायै, जात्यै, गम्भीरायै, अभाववर्जितायै, नागपाशधरामूर्तये, अगाधायै, नागकुण्डलायै, सुचक्रायै, चक्रमध्यस्थायै, चक्रकोणनिवासिन्यै, सर्वमन्त्रमयीविद्यायै, सर्वमन्त्राक्षरावलये, मधुस्रवायै, स्रवन्त्यै, भ्रामर्यै, भ्रमरालकायै, मातृमण्डलमध्यस्थायै, मातृमण्डलवासिन्यै, कुमारजनन्यै, क्रूरायै, सुमुख्यै, ज्वरनाशिन्यै, अतीतायै, विद्यमानायै, भाविन्यै, "तेजोऽसि" ॐप्रीतिमञ्जर्यै स्वाहा ८०० भक्तानां सिद्धिदात्री नलिनयुगकरा श्वेतपद्मासनस्था लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री । वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता

तारिणी । अक्रूरा च ग्रहवती विग्रहा ग्रहवर्जिता । रोहिणी भूमिगर्भा च कालभूः कालवर्जिता । कलङ्करहिता नारी चतुष्षष्ट्यभिधावती । जीर्णा च जीर्णवस्त्रा च नूतना नववल्लभा । अजरा नियतिः प्रीतिरतिरागविवर्धिनी । पञ्चवातगतेर्भिन्ना पञ्चश्लेष्माशयाधरा । पञ्चपित्तवती पंक्तिः पञ्चस्थानविभाविनी । ऋतुमती कामवती बहिःप्रस्राविणी त्र्यहा । रजःशुक्रधराशक्तिर्जरायुर्गर्भधारिणी । त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिः पुरवासिनी । अरागा शिवतत्त्वा च कामतत्त्वानु-

या भवानी नौम्यहं नौम्यहं त्वां हरिहरनमितां शारिकां नौमि नौमि ॥ ओं सर्वसौख्यवतीयुक्त्यै स्वाहा, आहारपरिणामिन्यै, पञ्चभूतानां निधानायै, भवसागरतारिण्यै, अक्रूरायै, ग्रहवत्यै, विग्रहायै, ग्रहवर्जितायै, रोहिण्यै, भूमिगर्भायै, कालभुवे, कालवर्जितायै, कलङ्करहितायै, नार्यै, चतुःषष्ट्यभिधावत्यै, जीर्णायै, जीर्णवस्त्रायै, नूतनायै, नववल्लभायै, अजरायै, नियत्यै, प्रीत्यै, अतिरागविवर्धिन्यै, पञ्चवातगतेर्भिन्नायै, पञ्चश्लेष्माशयाधरायै, पञ्चपित्तवतीपङ्क्त्यै, पञ्चस्थानविभाविन्यै, ऋतुमत्यै, कामवत्यै, बहिःप्रस्राविण्यै, त्र्यहायै, रजःशुक्रधराशक्तये, जरायवे, गर्भधारिण्यै, त्रिकालज्ञायै, त्रिलिङ्गायै, त्रिमूर्तये, पुरवासिन्यै, अरागायै, शिवतत्त्वायै, कामतत्त्वानुरागिण्यै,

रागिणी । प्राच्यवाची प्रतीचीदिगुदीचीदिग्विदिग्दिशा । "७०" अहंकृतिरहंकारा बालमाया बलिप्रिया । स्रुक्स्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता । माता मातामही तृप्तिः पितृमाता पितामही । स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया । स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी । शिशूत्सङ्गधरा दोला दोलाक्रीडाभिनन्दिनी । उर्वशी कदली केका विशिखा शिखिनर्तिनी । खट्वाङ्गधारिणी खट्वा बाणपुङ्खानुवर्तिनी । लक्ष्यप्राप्तिः काललक्ष्या लक्ष्या च शुभलक्षणा । वर्तिनी सुपथाचारा परिखा च

प्राच्यै, अवाच्यै, प्रतीचीदिशे, उदीचीदिशे, विदिग्दिशे, अहङ्कृतये, अहङ्कारायै, बालमायायै, बलिप्रियायै, स्रुचे, स्रुवायै, सामिधेन्यै, सुश्रद्धायै, श्राद्धदेवतायै, मात्रे, मातामह्यै, तृप्तये, पितृमात्रे, पितामह्यै, स्नुषायै, दौहित्रिण्यै, पुत्र्यै, पौत्र्यै, नप्त्र्यै, शिशुप्रियायै, स्तनदायै, स्तनधारायै, विश्वयोनये, स्तनन्धय्यै, शिशूत्सङ्गधरायै, दोलायै, दोलाक्रीडाभिनन्दिन्यै, उर्वश्यै, कदल्यै, केकायै, विशिखायै, शिखिनर्तिन्यै, खट्वाङ्गधारिण्यै, खट्वायै, बाणपुङ्खानुवर्तिन्यै, लक्ष्यप्राप्तये, काललक्ष्यायै, लक्ष्यायै, शुभलक्षणायै, वर्तिन्यै, सुपथाचारायै, परिखायै, खनिर्वृतये, प्राकारवलयायै, वेलायै, महोदधिमर्यादायै, पोषण्यै, शोषणीशक्तये, दीर्घकेश्यै, सुलोमशायै,

स्वनिर्वृतिः । प्राकारवलया वेला मर्यादा च महोदधौ । पोषणी शोषणीशक्तिर्दीर्घकेशी सुलोमशा । ललिता मांसला तन्वी
९००वेदवेदाङ्गधारिणी नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा । अक्षक्रीडारतिः शारी शारिका शुकभाषिणी । शाम्बरी गारुडीविद्या वारुणी वरुणार्चिता । वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा । मीनमूर्तिधरा मूर्त्ता वदान्या प्रतिमाश्रया । अष्टमूर्तिर्निधीशा च शालिग्रामशिला स्तुतिः । स्मृतिः संस्काररूपा च सुसंस्कारा च संस्कृतिः । प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका । इडा च

ललितायै, मांसलायै, "तेजोऽसि" तन्व्यै, स्वाहा ॥९००॥ रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेद्विनाशिनी भगवतीपादद्वयी सेव्यतामुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ ॐवेदवेदाङ्गधारिण्यै स्वाहा, नरासृक्पानमत्तायै, नरमुण्डास्थिभूषणायै, अक्षक्रीडारतये, शार्यै, शारिकायै, शुकभाषिण्यै, शाम्बर्यै, गारुडीविद्यायै, वारुण्यै, वरुणार्चितायै, वाराह्यै, तुण्डहस्तायै, दंष्ट्रोद्धृतवसुन्धरायै, मीनमूर्तिधरायै, मूर्तायै, वदान्यायै, प्रतिमाश्रयायै, अष्टमूर्त्तये निधीशायै, शालिग्रामशिलायै, स्तुतये, स्मृतये, संस्काररूपायै, सुसंस्कारायै, संस्कृतये, प्राकृतायै, देशभाषायै, गाथायै, गीत्यै, प्रहेलिकायै,

पिङ्गला पिङ्गा सुषुम्णा सूर्यवाहिनी । शशिस्रवा च तालुस्था काकिनी मृतजीविनी । अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिरा । स्थावरा जङ्गमादेवी कृतकर्मफलप्रदा । विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया । विश्वरूपा चिदानन्दा परंब्रह्मप्रबोधिनी । निर्विकारा च निर्वैरा विरतिः सत्त्ववर्धिनी । पुरुषा ज्ञानभिन्ना च क्षान्तिः कैवल्यदायिनी । विविक्तसेविनी प्रह्वा जनयित्री बहुश्रुतिः । निरीहा च समस्तेहा सर्वलोकैकसेविता । सेवा सेवाप्रिया सेव्या सेवाफलविवर्धिनी । कलौकल्किप्रिया काली दुष्टम्लेच्छविनाशिनी ।

इडायै, पिङ्गलायै, पिङ्गायै, सुषुम्णायै, सूर्यवाहिन्यै, शशिस्रवायै, तालुस्थायै, काकिन्यै, मृतजीविन्यै, अणुरूपायै, बृहद्रूपायै, लघुरूपायै, गुरुस्थिरायै, स्थावरायै, जङ्गमादेव्यै, कृतकर्मफलप्रदायै, विषयाक्रान्तदेहायै, निर्विशेषायै, जितेन्द्रियायै, विश्वरूपायै, चिदानन्दायै, परंब्रह्मप्रबोधिन्यै, निर्विकारायै, निर्वैरायै, विरत्यै, सत्त्ववर्धिन्यै, पुरुषायै, अज्ञानभिन्नायै, क्षान्तये, कैवल्यदायिन्यै, विविक्तसेविन्यै, प्रह्वायै, जनयित्र्यै, बहुश्रुतये, निरीहायै, समस्तेहायै, सर्वलोकैकसेवितायै, सेवायै, सेवाप्रियायै, सेव्यायै, सेवाफलविवर्धिन्यै, कलौकल्किप्रियायै, काल्यै, दुष्टम्लेच्छविनाशि-

प्रत्यञ्चा च धनुर्यष्टिः खड्गधारा दुरानतिः । अश्वप्लुतिश्च वल्गा च सृणिः सन्मत्तवारुणा । वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी । जयश्रीर्जयदीक्षा च जयस्था जयवर्धिनी । सौभाग्यसुभगाकारा सर्वसौभाग्यवर्धिनी । क्षेमङ्करी सिद्धिरूपा सत्कीर्तिः पथिदेवता । सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा । सर्वसिद्धिप्रदाशक्तिः सर्वमङ्गलमङ्गला १०००	न्यै, प्रत्यञ्चायै, धनुर्यष्ट्यै, खड्गधारायै, दुरानतये, अश्वप्लुतये वल्गायै, सृणये, सन्मत्तवारुणायै, वीरभुवे, वीरमात्रे, वीरसुवे, वीरनन्दिन्यै, जयश्रियै, जयदीक्षायै, जयस्थायै, जयवर्धिन्यै, सौभाग्यसुभगाकारायै, सर्वसौभाग्यवर्धिन्यै, क्षेमङ्कर्यै, सिद्धिरूपायै, सत्कीर्त्तये, पथिदेवतायै, सर्वतीर्थमयीमूर्तये, सर्वदेवमयीप्रभायै, सर्वसिद्धिप्रदाशक्तये, ॐ "तेजोऽसि" सर्वमङ्गलमङ्गलायै, स्वाहा ॥१०००॥

पुण्यं सहस्रनामेदमम्बायाः शिवभाषितम् । यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः । एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ तेजस्वी बलवान् शूरः शोकरोगविवर्जितः । यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः । यशांसि लभते नित्यं निश्चलां च शुभां श्रियम् ॥ सर्वपापविनिर्मुक्तो लोभक्रोधविवर्जितः । नित्यं बन्धुसुतादारापुत्रपौत्रमहोत्सवैः ॥ नन्दितः सेवितो भृत्यैर्बहुभिः शुचिमानसैः । विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ।

वैश्यस्तु धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् । इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ कन्यार्थी लभते कन्यां रूपशीलगुणान्विताम् । क्षेत्रं च बहुसस्यं स्याद्गावस्तु बहुदुग्धदाः ॥ नाशुभं नापदस्तस्य न भयं नृपशत्रुतः । जायते नाशुभा बुद्धिर्लभते कुलधुर्यताम् ॥ न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः । न पिशाचा न डाकिन्यो भूता व्यन्तरजम्भकाः ॥ बालग्रहाभिभूतानां बालानां शान्तिकारकम् । द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् ॥ लोहपाशैर्दृढैर्बद्धो बन्दी वेश्मनि दुर्गमे । तिष्ठञ्छृण्वन्पठन्मर्त्यो मुच्यते नात्र संशयः ॥ न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् । पश्यन्ति न हि ते शोकं वियोगं चिरजीविनः ॥ अन्धस्तु लभते दृष्टिं चक्षूरोगैर्न बाध्यते । बधिरः श्रुतिमाप्नोति मूको वाचं शुभां नरः ॥ पतद्गर्भा च या नारी स्थिरगर्भा च जायते । कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ पठनाच्छ्रवणाद्वापि दिव्यकाया भवन्ति ते । ये पठन्ति सदा मर्त्याः शुचिष्मन्तो जितेन्द्रियाः । अपुत्राः प्राप्नुयुः पुत्राञ्छृण्वन्तोपि न संशयः । महाव्याधिपरिग्रस्तास्तप्ता ये विविधैर्ज्वरैः । भूताभिषङ्गसञ्जातैश्चातुर्थिकतृतीयकैः ॥ अन्यैश्च दारुणै रोगैः पीड्यमानाश्च मानवाः । गतबाधाः प्रजायन्ते ते मुक्ता नात्र संशयः ॥ श्रुतग्रन्थधरो बालो दिव्यवादी कवीश्वरः । पठनाच्छ्रवणाद्वापि भवत्येव न संशयः ॥ अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः । ये पठन्ति सदा मर्त्या न ते वै दुःखभाजनाः ॥ नवरात्रं जिताहारो दृढभक्तिर्जितेन्द्रियः । चण्डिकायतने विद्वाञ्छुचिष्मान्मूर्तिसन्निधौ ॥ एकाकी तु शतावर्तं पठन्धीरश्च निर्भयः । साक्षाद्भगवती तस्मै प्रयच्छतीप्सितं फलम् ॥ सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये । पठनात्साधकस्याशु

सिद्धिर्भवति वाञ्छिता ॥ दशावर्तं पठेद्यस्तु भूमिशायी नरः शुचिः । स्वप्ने मूर्तिमतीं देवीं वरदां सोपि पश्यति ॥ आवर्तनसहस्रैर्ये पठन्ति पुरुषोत्तमाः । ते सिद्धाः सिद्धिदा लोके शापानुग्रहयोः क्षमाः ॥ कवित्वं संस्कृतौ तेषां शास्त्राणां विकृतौ स्वतः । शक्तिः प्रोन्मील्यते स्वान्तेऽप्यनधीतेषु भारती ॥ नखरागशिरोरत्नद्विगुणीकृतरोचिषः । प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महेश्वराः ॥ रोचनालिखितं भूर्जे कुङ्कुमेन शुभे दिने । धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाः ॥ विप्रांश्च वरनारीश्च धूपैः कुङ्कुमचन्दनैः । क्षीरखण्डाज्यभोज्यैश्च भोजयित्वा सुभूषिताः ॥ बध्नन्ति ये महारक्षां बालानां च विशेषतः । भवन्ति नृपपूज्यास्ते कीर्तिभाजो यशस्विनः ॥ शत्रुतो न भयं तेषां दुर्जनेभ्यो न राजतः । न च दाराभिचारेभ्यो न दारिद्र्यान्न दुर्गतेः ॥ महार्णवे महानद्यां पोतस्थेपि न भीः क्वचित् । रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते ॥ नृपाश्च वशतां यान्ति नृपमान्याश्च ये नराः । सर्वत्र पूजिता लोके बहुमानपुरःसरम् ॥ रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः । यौवनाक्रान्तदेहास्ताञ्छ्रयन्ते वामलोचनाः ॥ लिखितं मूर्ध्नि कण्ठे वा धारयेद्यो रणे शुचिः सप्तधा युध्यमानं तं प्रतियोद्धा न पश्यति ॥ केतौ वा दुन्दुभौ येषां तिष्ठेद्धै लिखितं रणे । महासैन्यपरिग्रस्तान्कान्दिशीकान्हतौजसः ॥ विचेतनान्विमूढांश्च शस्त्रकृत्यविवर्जितान् । निर्जित्य शत्रुसङ्घांस्तु लभते विजयं ध्रुवम् ॥ नाभिचारो न शापश्च बाणवीरादिकीलनम् । डाकिनी पूतना कृत्या महामारी च शाकिनी ॥ भूताः प्रेताः पिशाचाश्च रक्षांसि व्यन्तरादयः । न विशन्ति गृहे देहे लिखितं यत्र तिष्ठति ॥ न शस्त्रानलतोयौघाद्भयं तस्योपजायते । दुर्वृत्तानां

च पापानां बलहानिकरं परम् ॥ मन्दुराकरिशालासु गवां गोष्ठे समाहितः । पठेत्तद्दोपशान्त्यर्थं कूटपाककलिनाशनम् ॥ यमदूतान्न पश्यन्ति न ते निरययातनाम् । प्राप्नुवन्त्यक्षयं प्रान्ते शिवलोकं सनातनम् ॥ सर्वबाधासु घोरासु सर्वदुःखनिवारणम् । सर्वमङ्गल्यकृत्स्वर्ग्यं पठितव्यं समाहितैः ॥ श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥

पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् । चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा विद्या तीर्थं नातः परं परम् । ते धन्याः कृतपुण्यास्ते त एव भुवि पूजिताः । एकभावं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् । देवतानां देवता या ब्रह्माद्यैर्या च पूजिता । भूयात्सा वरदा लोके साधूनां विश्वमङ्गला । एतामेव पुराराध्य विद्यां त्रिपुरभैरवीम् । त्रैलोक्यमोहनं रूपमकार्षीद्भगवद्धरिः ॥ मायाकुण्डलिनी० अनेन मन्त्रपाठेन० ॥ इति श्रीरुद्रयामले तन्त्रे नन्दिकेश्वरसंवादे महाप्रभावो भवानीनामसहस्रस्तवराजः समाप्तः ॥

अथ इन्द्राक्षीस्तोत्रम् ॥

ॐ अस्य श्रीइन्द्राक्षीस्तोत्रमन्त्रस्य, पुरन्दर ऋषिः, अनुष्टुप् छन्दः, श्रीइन्द्राक्षीभगवती देवता, भुवनेश्वरी शक्तिः, माहेश्वरी कीलकं, गायत्री सावित्री सरस्वती कवचं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं अमुककामनासिद्ध्यर्थं पाठे विनियोगः ॥ ॥ लक्ष्म्यै अङ्गुष्ठाभ्यां नमः, भुवनेश्वर्यै तर्जनीभ्यां नमः, माहेश्वर्यै मध्यमाभ्यां नमः, वज्रहस्तायै अनामिकाभ्यां नमः, सहस्रनयनायै कनिष्ठिकाभ्यां नमः, इन्द्राक्षीभगवत्यै करतलकरपृष्ठाभ्यां नमः ॥ इति करन्यासः ॥

अथ षडङ्गन्यासः ॥ लक्ष्म्यै हृदयाय नमः, भुवनेश्वर्यै शिरसे स्वाहा, माहेश्वर्यै शिखायै वषट्, वज्रहस्तायै कवचाय हुं, सहस्रनयनायै नेत्राभ्यां वौषट्, इन्द्राक्षीभगवत्यै अस्त्राय फट् ॥ प्राणायामः ॥ ॥ ध्यानम् ॥ ॥ ॐ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रधरां शुभाम् । वामे वज्रधरां सव्यहस्तेऽभयवरप्रदाम् ॥ सहस्रनेत्रां सूर्याभां नानालङ्कारभूषिताम् । प्रसन्नवदनां नित्यामप्सरोगणसेविताम् ॥ श्रीदुर्गां सौम्यवदनां पाशाङ्कुशधरां पराम् । त्रैलोक्यमोहिनीं देवीं भवानीं प्रणमाम्यहम् ॥ ॥

॥ इन्द्र उवाच ॥ इन्द्राक्षी नाम सा देवी देवता समुदाहृता । गौरी शाकम्भरी देवी दुर्गानाम्नेति विश्रुता ॥ कात्यायनी महादेवी चण्डघण्टा महतपा । सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी ॥ नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला । अग्निज्वाला रुद्रमुखी कालरात्री तपस्विनी ॥ मेघश्यामा सहस्राक्षी विष्णुमाया जलोदरी । महोदरी मुक्तकेशी घोररूपा महाबला ॥ आनन्दा भद्रजानन्दा रोगहर्त्री शिवप्रिया । शिवदूती कराली च प्रत्यक्षपरमेश्वरी ॥ इन्द्राणी चन्द्ररूपा च इन्द्रशक्तिः परायणा । महिषासुरसंहर्त्री चामुण्डा गर्भदेवता ॥ वाराही नारसिंही च भीमा भैरवनादिनी । श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥ अनन्ता विजया पूर्णा मनस्तोषाऽपराजिता । भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा ॥ शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी ॥

एतैर्नामपदैर्दिव्यैः स्तुता शक्रेण धीमता । आयुरारोग्यमैश्वर्याऽक्षयसम्पत्तिकारकम् ॥ क्षयापस्मारकुष्ठादितापज्वरनिवारकम् । शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् । आवर्तयेत्सहस्रेण लभते वाञ्छितं फलम् । राजा वशमवाप्नोति सत्यमेव न

संशयः । लक्षमेकं जपेद्यस्तु साक्षाद्देवीं स पश्यति । त्रिकालं पठते नित्यं धनधान्यांश्च सम्पदः । अर्धरात्रे पठेन्नित्यं मुच्यते व्याधिबन्धनात् । ऐन्द्रस्तोत्रमिदं पुण्यं जपे तु फलवर्धनम् । विनाशाय तु रोगाणामपमृत्युहराय च । राज्यार्थी लभते राज्यं धनार्थी विपुलं धनम् । इच्छाकामं तु कामार्थी धर्मार्थी धर्ममव्ययम् । विद्यार्थी लभते विद्यां मोक्षार्थी परमं पदम् ॥ इन्द्रेण कथितं स्तोत्रं सत्यमेव न संशयः ॥ ॥ या माया मधुकैटभप्रमथिनी या माहिषोन्मूलिनी । या धूम्रेक्षणचण्डमुण्डमथिनी या रक्तबीजाशनी ॥ शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा । सा देवी नवकोटिमूर्तिसहिता मां पातु माहेश्वरी ॥ ॥ जप्तं पापहरं नुतं बलकरं सम्पूजितं श्रीकरं ध्यातं मानकरं स्तुतं धनकरं सम्भाषितं सिद्धिदम् । गीतं सुन्दरि वाञ्छितं प्रतनुते ते पादपद्मद्वयं भक्तानां भवभीतिभञ्जनकरं सिद्ध्यष्टदं पातु नः ॥ ॥ माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ अनेन मन्त्रपाठेन आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीइष्टदेवीप्रीत्यर्थं भगवती अमा कामा चार्वङ्गी टङ्कधारिणी तारा पार्वती यक्षिणी श्रीशारिकाभगवती श्रीशारदाभगवती श्रीमहाराज्ञी भगवती श्रीज्वालाभगवती व्रीडाभगवती वैखरीभगवती वितस्ताभगवती गङ्गाभगवती यमुनाभगवती कालिकाभगवती सिद्धलक्ष्मीः महालक्ष्मीः महात्रिपुरसुन्दरी सहस्रनाम्नी देवी भवानी सपरिवारा सवाहना सायुधा साङ्गा प्रीयतां प्रीतास्तु ॥ इति इन्द्राक्षीस्तोत्रं सम्पूर्णम् ॥

हमारे क्रेयपुस्तक मिलने का पताः—

पं० केशवभट्टज्योतिषी पाठशाला टीचर, जिल्ला रैणावारी, महल्ला भाग ज्योगीलङ्कार कश्मीर—श्रीनगर.

क्रेयपुस्तकसूची	मूल्यं
(१) नित्यकर्मविधिः (स्नानविधि सन्ध्योपासना, नैवेद्यमन्त्र भोजनविधि पञ्चगव्यविधि हिन्दी में इति कर्तव्यता समेतः)	=)
(२) नित्यकर्मविधिः (उपर्युक्तविषय तथा विष्णुपञ्चायतन-पूजा गणेशकवच गुरुस्तुति गायत्रीलीला गौरीस्तुति मुकुन्दमाला समेतः)	।=)
(३) शिवपूजा (बहुरूपगर्भ, महिम्नःपार-शिवकवच-शिव-निर्वाण—व्याप्तचराचरअतिभीषण—षडक्षरस्तुति-पञ्चा-क्षरस्तुति—दीनाक्रन्द—शिवक्षमापन—कैवल्योपनिषत्—शिवपूजागणेशस्तवराजात्मिका)	।=)
(४) गणेशदुर्गास्तोत्रावली (लाक्षासिन्दूरवर्ण-अद्रिराजज्येष्ठ-पुत्र—एकदन्तमीशपुत्र—इति गणेशस्तोत्रत्रयगणपतिवि-द्या-देवीध्यानरत्नमालाशारिकास्तोत्र-ब्राह्मीविद्यात्मिका)	।-)
(५) पञ्चस्तवीसमेता-सौन्दर्यलहरी	।)॥
(६) चमानुवाक्यम्	=)।
(७) रुद्रपञ्चकम्	।)
(८) कर्मकाण्डपुस्तकम् (संवत्सरिकपितृकर्मोपयोगि)	।।।=)
(९) वेदकल्पद्रुमः (हवनक्रियोपयोगी वास्तुप्रतिष्ठा, चातुर्मा-स्योद्यापनविधि-गण्डान्तशान्ति-ग्रहशान्ति-वास्तुप्रतिष्ठा-कन्यासंस्कार तुलादानाद्यात्मकः)	१)
(१०) मेखलापुस्तकम् (ऋचक-विवाहपद्धति उपनयनपद्धति अग्निकुण्डपूजाकन्यासंस्कार-नान्दीमुखश्राद्ध-इहकीलि-पूजाद्यात्मकम्)	१॥)

(११) वटुकपूजा (कलशपूजा-वैश्वदेवव्याहृत्यादियुता काश्मीरिकशिवरात्रिदिने अतीवोपयोगिनी गृहस्थाश्रमस्थितानां धार्मिकाणाम्) ... ... ।=

(१२) पार्थिवेश्वरपूजा (कलशपूजा-वैश्वदेवव्याहृत्यादियुता शिवोपासकानामतीवोपयोगिनी) ... ... ।=

(१३) उपदेशपञ्चकम् (शङ्करस्वामिरचितम्, तथा काश्मीरिकमहात्मना विरचितया रत्नप्रभाटीकयालङ्कृतम्, सम्पूर्णवासिष्ठाशयगर्भम्, उपनिषत्सारप्रायम् अतीवोपयोगि विवेकवैराग्ययुक्तानां महात्मनाम्) ... ... ≡)

(१४) भक्तविवेकसारः (अज्ञानबोधिनी-आत्मबोध-सटीका-प्रह्लादस्तुतिः सटीक—मुचुकुन्दस्तुतिः सटीक-रासक्रीडा पञ्चाध्यायी सटीका-गोपीस्तुतिःसटीकगोपीयुगलगीता-सटीकभ्रमरगीता-सटीक-भिक्षुगीता-गणेशस्तुति-शैवीयप्रातःकृत्यविधि-महागायत्रीस्तुति-मुकुन्दमाला-कृष्णलीलास्तुति-गोविन्दाष्टक-जयनारायणस्तोत्र भजगोविन्दस्तोत्र-अङ्गनामङ्गना-विचारद्वादशपञ्जरिका-कृष्णजन्मस्तुति-नारायणार्तत्राणस्तुति-नारायणोपनिषत्-शैवीब्राह्मीविद्या-गलेकालेत-इतिशिवस्तुति—जटायुकृतरामस्तुति—त्रिपुरसुन्दरीशारिकाज्वाला-राज्ञीनां स्तुतयः सूर्यादिनवग्रहाणां पृथक् पृथक्स्तुति-पराप्रवेशिकात्मकः) ॥=)

(१५) योगवासिष्ठसारः (मूलमात्रम्) ... ... ≡)

(१६) भवानीनामसहस्रस्तुतिः(स्वाहाकारयुता इन्द्राक्षीयुता च) ।-)

(१७) कलशस्थापनोद्धारः (काश्मीरिकानां देवपित्रोः क्रियोपयोगी) ... ...